धर्मरत्न बज्राचार्य सुरत श्री महाबिहार

II-111

ओं नमो भगवद्दे अर्हते महावीरवर्धमानस्वामिने ॥ अथ मया कृतमकृत्रिमसमस्तमहावज्रमहाविद्यासिद्धकृत
महाविद्यासिद्धमहावज्रमहाविद्यानेमहावज्रकल्पदुमसमस्तकृतमहावज्रपूर्विकसि
द्धिनयज्ञानसिद्धमहावज्रवानिकर्मकल्पमिहोत्तमहावज्रमहाविद्यानेमहावज्रमन्त्रसमाहृत्य ॥ गरुड
देवानासिद्धस्वरूपनेमहावज्रसिंहसनेकानिनियूतशतसहस्रमहाविद्यासिद्धिप्रथमदर्शनाद्यनिमहाव
ज्रवद्यज्ञाधिष्ठानाधिष्ठित ॥ सर्वद्रव्यसमस्तमंत्रयंत्रसहस्रनामिद्याकल्पकुलाभिनिर्हारोधिसत्वक
टिनियूतशतसमालावंत्रवरेकजानिपनिवहेसर्ववर्णकल्पनूतनाद्यासंभाक्षंयोगेमहाह्रासय
देवाक्षावज्रविमानसमस्वस्तमाधिदुष्टस्वरूपनिकूवतमतापनिहायसिद्धमंत्रेकविनश्यमवलमूल

सर्वसहस्रलक्षविनवासिनानूपवेगविश्वनमयूरादेवगमहोत्सवनदेवनाथनिहानपतिहाध्यिसमवाग
नेत्रनेकदूतशतविद्धस्वदेवनभागतमहायुद्धसमाचनाविमाक्षमुखप्रत्यनिस्तमाग्रवस्तिनाहिस्त
वनिकवेश्यागमागतनियरेसमासमिक्षणवद्धेरत्यसुगतवद्धुमालासनिकल्पनाभद्रिनापक्षसिं
द्धिवस्विधिक्रयध्यिविज्ञानविनश्यैवानेन ॥ तदद्धा ॥ वज्रगर्हेनवनामवेधिसत्वेनाबद्धनेवतवाबद्धगन
वज्रनवावज्रसंविनावावज्रसक्तेनवावद्धसंगहकेनवावद्धनोर्यनवनवावद्धविकूविकनवावद्ध
कूद्धवावद्धसाक्षिनिनावावद्धोकूसनवासवद्धनवद्धत्यनेनवावद्धकुलनावानमोक्षिमध्येमा
हासत्वनाग्रवैपमदेवंतुलागानिहिं धिसत्वकनिनियूतसतसहस्रार्धसंवहसेवमहाग्रव



ओं दक्षिणस्यां नीलवर्णं रक्षनिसूदानं गणं महापनिसरा मर्कांयाक्षीं अस्यनेसद्रासर्वसिद्धिर
वल्लभा ४ पूजयामहावनिस्यगासर्वगणसिद्धिवल्लुकेसूखेमस्यनिगुविघ्नाकार्यवापिनस्व
निसवपापनसंसय॥पूजयित्वासवासिद्धीधनधान्येश्वरोभवेत्॥ओं दक्षयवनवाधिपूजनि
यारुविघ्नानिगुविद्यासयत्रयमुक्तियावापूजाफलवासर्वसत्वानांमोक्षार्थं
मदेन॥सरविनवरुवनिर्हसवकार्यविवर्जितासाजानावसगणस्वस्मनेष्टपूजमहाजनानां
हीवशंसत्रेस्त्रीपूजयेत्सिद्धिविवर्धनं॥सिद्धाकेसवदस्त्रीवपविद्ध॥सवर्मंकुरे॥सवर्व

समयस्मरेत्तेनिनस्ववचनैयथादृष्टस्वप्रार्थनवाधनंसवपापहरंसियात्॥किंतीक्ष्णेवनस्यनिय
त्यसिनाकृत्येवच॥सवग्रहविनाशार्थंशाषिनास्तनमस्कुरे॥सर्वकामेददाहूंफोंठवयशक्रु
निमेम॥नंदिदानिंपवस्त्रीमिलनसैघागृह्णानुमानम॥सवगणगानांनमानमष्टसवबुधश्च
मिस्वसत्ववृद्धमसैघस्व॥नंयथाजंविघ्नसगहेविघ्नसविमले॥जंविमरगहे॥विमले॥जयग
हे॥बजाजासगहे॥गनिगहने॥गगननविस्यवने॥सवपापविस्यवने॥जंभुनवनिगगन
विवासिनि॥गगनसिनि॥गीसिरगमसिरगहसिरगहरगजासिरगगसिरगभुसिरगहिर

गहरगमनिरगतेरगहरगुहरगुह्यगुह्यतिरवरेश्वर
सर्वसत्वोज्जयविजयाजयवतिभ्यःस्वाहा ओं विगतक्रोधगहनेतत्रोत्तिष्ठविरूढ
तिरोमितिपितिधितिसर्वमंत्राकर्षनिःसर्वसत्वान्यमथनिःसर्वसत्वानाकर्षय
सर्वदुष्टयक्षसर्वग्रहाधिपत्यंकुरुकुरुविरुविरुदितिरविविश्ववरूपधिमति ८
मविरविरिरकमलविमलोज्जयजयावहोज्जयवतिविश्वरववतिरुगवतितत्तनमकू
तमोसाधनिवहविविधविधिनवरूपाक्षतिनिहरणवतिमाहाविद्याहवितक्षारमसर्वसत्व

सर्वमनोसर्वनसर्वपापविशोधनिःक्लेशस्वस्तरमतिरतक्षरसर्वसत्वोनाथाश्वरनाथानन्त
तयनानन्तरपत्रायडोपतिभावयष्टसर्वदुःखक्षयष्टचक्षुस्वक्षुरचक्षुनिरवरणविशुद्धक्षुनिर्म
तिनिर्विजयवाहिनिःक्लेशस्मरस्वस्तरश्रायुष्पतिनिःसर्वसर्वयमथनिःसर्वदेवगनपूजितु
र्विजिरर्षिसिरसमनोवलोकितोपकरसपक्षुपक्षविशुद्धासर्वपापविशोधनिःक्लेशस्वस्तिधते
समरसमस्तसत्वस्वलेचातयदक्षानपूसत्रश्रासामसन्यस्तोनावकूतस्त्रीवपूधत्रजयकूम
डिनिरवलदोकूसोऽवनविशुद्धशुद्धसोमयाराजरहस्यरहितिकुलरनक्षसविशुद्धापविनम

सर्वाविघ्नविनाशनिसमनोत्कासमनुस्वरविसर्गविगतभयैसर्वविगतभयविनाशनिःक्षिप्तोरस
वपापविशुद्धेसमस्तविगतनेजवनिःनेजोवनिःवज्रवज्रवनितेसोक्षाधिष्ठितस्वाहासर्वनथागतमुद
हिधिकस्वाहासर्वबुधबोधिसत्वाहिधिकस्वाहासर्वदवताहिधिकस्वाहासर्वनथागतहृदयधिष्ठितहृद
यस्वाहासर्वनथागतहृदयसमयनिहृदयस्वाहाऽऽंदेऽऽंन्दवतिऽऽंन्द्रयवस्थिरेस्वाहासर्वकर्मावरणवि १०
शुद्धनेत्रेस्वाहासर्वतथागतमुद्रेनायेस्वाहासर्वधर्मवशंवशंकरेवरविशुद्धेस्वाहा
यमान्तकस्वाहाऽऽमरयूरिनेननक्रोधनायस्वाहाहयग्रीवनायस्वाहाऽवोलोकितनायस्वाहाऽमोघपा

महासाधनायस्वाहाऽऽर्यजयस्वाहाऽऽर्यपद्मस्वाहाऽनागविलोकितायस्वाहाऽदर्शनाख्यः
स्वाहानागहस्तयस्वाहायक्षगणेश्वरस्वाहागंधर्वगणाख्यस्वाहाऽऽसुरगणाख्यस्वाहाऽऽर
क्षगणाख्यस्वाहागरुडगणाख्यस्वाहाकिन्नरगणाख्यस्वाहामहोरगगणाख्यस्वाहामनुष्यग
णाख्यस्वाहामनुष्यभूतेभ्यस्वाहासर्वभूतेभ्यस्वाहासर्वग्रहेभ्यस्वाहाधनेश्वरस्वाहा
सर्वधनधान्येश्वरस्वाहासर्वपुत्रेश्वरस्वाहासर्वकामेश्वरस्वाहासर्वपुत्रनेश्वरस्वाहास
र्वविकटपूतनाख्यस्वाहासर्वदुष्टग्रहेभ्यस्वाहाऽऽंधकरस्वाहाऽऽंकुरस्वाहाऽऽंकुर
स्वाहासर्वशत्रुभ्यस्वाहादऽऽंडरस्वाहासर्वदुष्टानांस्वाहाऽऽंपंचेरसर्वपथाधिकपथाभिलाषा

ह्रायमस्माहिनघिरात्रुघातलावंशातयस्वाहा॥सवरसूचिलानांस्वाहा॥ठक्तिनायस्वाहा॥पङ्क्तिनां
यस्वाहा॥दिफठानायेस्वाहा॥समंनहुंदायस्वाहा॥मानिहुंदायस्वाहा॥पूनहुंदायस्वाहा॥हंसंनहुंद
यस्वाहा॥महासमंनहुंदायेस्वाहा॥कालायस्वाहा॥मागकालायस्वाहा॥नहगनायस्वाहा॥यक्षिणी
नायस्वाहा॥वाक्षसीनांस्वाहा॥धनधिनावद्राक्षिनिनांस्वाहा॥ओंकाशीमहुगनांस्वाहा॥सहुगा ११
समनिनांस्वाहा॥सहुवाशिनीयस्वाहा॥सानिवसानांयस्वाहा॥दिवसमवसानायस्वाहा॥नि
सथ्यवसानांयस्वाहा॥वेसावेसानांयस्वाहा॥वेसावेसानांस्वाहा॥गहवरेरायस्वाहा॥गंगाकालै
मोहसंभनियस्वाहा॥नेरस्वाहा॥वूसरस्वाहा॥ओंस्वाहा॥स्वःस्वाहा॥हूंहूंस्वाहा॥ॐवःस्वाहा॥विसिरस्वा

स्वटिरस्वाहा॥विटिरस्वाहा॥धसनियस्वाहा॥धासनियस्वाहा॥ष्ठनीस्वाहा॥नजोवायूस्वाहा॥विसि
रस्वाहा॥सिसिरस्वाहा॥वक्षरस्वाहा॥मगुरवधेस्वाहा॥सिंहोवैंधस्वाहा॥सवीकृंहंहंयस्वा
हा॥हंकंयस्वाहा॥छिंद्रस्वाहा॥छिंद्रस्वाहा॥हंजेंयस्वाहा॥गंयस्वाहा॥हंकंयस्वाहा॥वैंध
रस्वाहा॥मोहयस्वाहा॥सनिवेंगुंडस्वाहा॥हर्यंसर्यंवेंगुंडस्वाहा॥सावंसिस्वाहा॥विसावंसिस्वाहा॥
वंडुरपूविंडस्वाहा॥गृहंत्यस्वाहा॥नभंतयस्वाहा॥पिसाचंयस्वाहा॥विसाचयस्वाहा॥शिवंत्यस्वाहा
सानियस्वाहा॥यस्मयमेंयस्वाहा॥शिवंकसियाहा॥सहंसियाहा॥सानिकसियाहा॥पृष्ठिंकसि
स्वाहा॥वंवंवंसियाहा॥शीकसियाहा॥शीवंछनकसियस्वाहा॥शीतोविनिकासियाहा॥मंचिस्वाहा

धिमिनाहिंसित्वा॥ कृत्वा॥ कायेत्वा॥ होकृत्वा॥ सेवमस्तायंमिसरासाम्मिताविद्यावाहीकृत्वंकृत्वा॥
संग्रामम्मध्येवर्तिष्यीचकाङ्किनेवसंग्रामंवर्तमानंवदनयाप्रावल्कृं
नंगानकृंतिवा॥ कृत्वासेवसंवत्सरंराजानंकृंतिवा॥ प्रवेदिमस्तावा॥ कृत्वाक्षान्तावनकृंयंमस्ताः
विद्यालोहीसवनंआगनहृदयम्डाधिष्ठितोपयन्तश्चवनिभसंयिनंवा॥ सवनंआगनहृदयत्र १४
षड्डंत्यायविभक्तासंयक्रिमसमयंशरीत्यायकृंवा॥ गंसंडपंधनांवसिंकृत्वाग्रमांसलाना
मथायंहिनाय्यंकामायदंकृत्वा॥ यंःकश्चित्सहोवाकृंगकृंयंमाहावनिसरासम्मिताविद्यासंहार्य
थाविभिनासिंखित्वावाहोकृंडंवाभसंयिष्यतिं॥ सवनंआगनकायकृंतिवदिनव्या॥ सवनं

यागवजकायकृंतिवदिनव्या॥ सवनंआगनंवाऊंगार्हकृंतिवदिनव्या॥ सवनंआगनंनकृंतिवदिनव्या॥
हासिताद्यिसाविसकृंतिवदिनव्या॥ अरुंधकंवंवकृंतिवदिनव्या॥ सवनंवीगतुंभपमंथनकृंतिवै
दिनव्या॥ सवनंपवसनंदिनंहननकृंतिवदिनव्या॥ सवनंसकंगहननंविलोधनंकृंतिवद्रिं॥ किमी
तिपूर्वंयतिहनंसत्रावाकृंदाअरन्वेतुमस्मीन्यृषिविषदंआहिंभूसंभ्रद्धकथागनंकुलसिक्षा
खंडुकंअदलादायीसखायदासत्रासकं॥ सधिकंवतुदिसिकंगदाधकंवंडुद्धवनंवोकृंसिं
कंकृत्वासुवंमधिकायंहरायतिं॥ यावद्रुपसेदासमयंनसमहतिंवाविनास्यंछमहतिंदुः
खांनीवांकंडंकांधसावदनामनहवतिं॥ सनयंवीरंनाआरयसायंआरयतिंगसंभमकृंम

दृशं किमत्र कथ्यतां यदेकथं निनिंदवाग्वदन्॥ततस्तदुक्तमेतनाथमस्तकस्थसदाद्रुमा॥यम
स्यधर्मराजस्यछंदवंदनमकुर्वना॥स्यंदवंमतासत्यउत्पन्नानलकंसकुरुवंविषस्यनोमदूतेनो
क्तानतकंकुरुध्वं॥कस्मिंजायस्यदक्षियंसत्यायहिंसाविकृतो॥सधिंनाध्वंसवंपुनर्यातिसत्या
लयं॥यमाधिपधर्मराजावक्रूरदूतविलिंगिन॥मत्पधिकामयंद्वाक्यमतावयाद्रुमकं॥तथाधातुस
तेवद्रु॥स्रुवेजुहूंनिशम्हनिशम्यंवं॥नथासत्याहुतंकायपतिसतावज्रकठकं॥अथतुनतकपाल
कायक्षा॥यमनाथधर्मराजस्यछंदवंदनमकुर्वन॥कथमियद्वपतिससंछ्यूत्र॥धर्मराजउवा
च॥वनिपसमालयंनेधर्मुसनगछनि॥इमनिं॥सगनिंगछतवासपतिससालावविन॥यूयंन

स्कपालावेगछथपूछसावनिं॥तदुक्तथमस्तकूदंवनं॥पतिवासिनं॥तदस्यासवसत्वपूमतिवि
लोकविधथा॥अथतयमपुत्रवायमस्यधर्मिराजस्याग्यया॥तस्यामवत्याप्रूछसावनिगतो॥कप
श्चनिष्कानतुराजश्चानिससियेते॥तत्रकूटंसमतनयंकठासासमाकुरा॥ततंगतिसंपश्चतियति
सत्यावछकछकं॥देवानामग्यंगंधर्वायक्षतोक्षसश्चिन्नस॥पतिवाच्यसिमतनपूजाकुर्वतेनूलयात
यावतस्यतेयज्ञे॥पतिसतकूटंतिनास्त्यावनं॥अथतेयक्षपूनसागत्यमस्यधर्मराजस्यैमि
त्र्यंविरुद्धेशोद्यतिसमे॥एवंमतदूवयथात्वयाकिल्किनं॥संमनंतसोचितेस्मिन्ववनपथे
वसानेतमतासत्वकूत्रासकंगतीसंविजयंतायतिसंपूदवषपन्न॥ततहतुनापतिसस

पूर्वदेवपूजनक्रियते॥तदनहिमहाब्राह्मणपतिक्षेत्रपूर्वस्मादवश्यमेवयंमहापतिसाधवश्यं
नेष्यतिखिनेष्यपेअविधिनानित्यंगतीसगतांकृत्वाधरण्यिकव्या॥सनित्यंसर्वयासनइग
खस्यष्ठपतिमर्द्यासर्वेशगतिहयहैसवल्लउक्तसति॥नवधिपूनासक्रयातन्तुकिमिनिखिघ्नापतिक्षोः
पूर्वमहाब्राह्मणहिंगुमदनेमहानगतवचविमस्तांखानामणुक्षिमहाधनकनसमद्धापतिपूर्वकाः
अकाष्ठागासस्यन्नोवक्रव॥समहासाधक्षतिरक्षानवान॥रथस्तमहासार्थवोक्षयानपावमासाघ्यमहा
समुद्रवनिर्द्रियावनिमिक्षिनेःसारस्यधेरवेकर्त्रु॥विनासयिकुकाहानामास्यसंरुक्षश्चामहानगा
जीनास्यर्दकूर्तिखिघुरुक्षासनिमस्तेजगतिवज्राहनीपवर्षयिकुमार्वेष्य॥नतुरुक्षवनिजोमरुता

रु॥खनाख्याहनचिल्लसक्षहातनागसंज्ञारुविघुत्कावजासनिवाहजंति॥नतेषांनिमिक्षिरे॥यानमवरु
ब्रुदक्षुमहातमस्कोहानास्वर्द्रुकाठमासत्रु॥नदेवताविशेषनयावपति॥नवकथिरुक्षीपतिग्रहांरुवे
ति॥तत्रुरुसाथवाहस्यगम्यकतृणमिदंवचनमब्रुवन॥पतिग्रायत्यमहासत्वमवयोसयामहाहयान
रथखलुमहासार्थवाहादृढविल्लमहासंनि॥वलिजोवलिजाविरुक्तिरुहानिदंवक्यासयामहाहयान्र
माहाहेमाक्षवाहजोखवोथीसर्वोब्रजन्यरहंवेमावयिष्यामिस्रोहरवमहाहपत॥त्रकोषीसमनसाहस्या
वलिजऽऽदंवचनमब्रुवनानेनमहासत्वब्रुवहिंगामविघुत॥यावक्रिविनमहामकंखस्यशावोमहाः
मतकक्षगोहानमहत्स्यंपक्षात्वंकिंकसिष्यसि॥तत्रसाथवनिरुक्षोमिसीविघानेदाहरेत॥अस्मिन

नमस्कारविधायिनिसत्तानामविघ्नानांसद्भावेसत्यसाक्षेनाहंमास्याभिरतइत्या
खमाख्यायिकानामतेमहासाधर्मिकाहरूयोंवेसायामिमांमहाविद्यासाधयिष्यामिइत्युक्त्वा श्मशानवासिनोंकंका
लिकाख्यांसमनन्तरमेवश्मशानवासिनमाम्रस्यामस्यावस्थानेसत्यांमहाविद्यासाधयन्तींसर्वेभवन्तोनिमित्तानिपश्य
न्तुमेकेत्याहुरेकेत्वेवमाहुरनागतमेतन्मनसाज्ञास्यामीतिकेचिदवोचन्यदिपुनाकुमारा १८
ब्रूयुस्तेवंसिद्धिर्भविष्यतीत्यस्यांप्रवेमहाविद्यासाधयन्तींमातंगविद्यासाधयन्तींवनदेवतांसाधयन्तीं
सर्वांगसाधकस्वसाधिकाकुलमातानोमहतिमाहत्सलनदीपयाचितकंतिहानवतीयंमहाविद्याः
मातंगसिद्धसेवकथागतोविघ्नानेनहेतुनाकंयंमहाविद्यांसाधयेत्यवश्यंमहाविद्या

मयंपुनाश्मशानवासिनाकंकालसंधिविद्यासर्ववानुगानाकालमयविद्यादर्शनीयंनामयंति॥सवदूवस
न्त्यामन्यंविग्रहविवादंकयंतिमेवंधिनि॥सवदंसमसकसहयाकंजानाविविधसर्पा॥सस्यविनाः
सकानपरुवंतिनापसर्पंगच्छंति॥सवरूक्षचिलाद्यागपक्षिणोद्रुविनश्यंति॥सवानिवपूंष्यकस्प
नवनस्यशोषविसस्यादिन्वहिवज्रेन॥सससानिस्यादूनिवरुविध्यंति॥सस्यशावपतिपाचिनाम्रि
विध्यंति॥अक्षतिदृष्टनादृष्टिदोषा॥सवनसेवंनहविध्यंति॥नाकालवृ
ष्टिंयवनस्मेविद्येयमहानागासनसस्यशावकालेनकालेवर्षमासास्सजंति॥यासिमंधविद्यंसा
धयेत्यमहानागासनसस्यशावकालेनकालेवर्षमासास्सजंति॥यासिमंधविद्यंसा
धयेत्यमहाविद्यांसाधयेत्यमहाविद्यांसाधयेत्यमहाविद्यांसाध

त्वामहायुजास्तत्कालं कृत्वानानाप्रकारैर्नानाद्रव्यैर्नानावर्णैर्नानापरिवृद्धयेत्यादिना प्रकारेण
सिद्धजातसवस्तुभिर्नानाविधैर्बहुभिर्वा यत्पूर्वसंज्ञैर्निहिवा यत्नानाहि॥प्रदक्षिणीकर्तव्या॥तत्रैकस्मि
न्नलास्त्वानायथाविधिनानसीपरिपूर्णायेत्यादि॥नोदेवताभ्यकुङ्कुमपत्रैर्वा॥अथवायेथा
विधिनासिद्धयेत्तथाशतसहस्रंवापूर्णाधिकतरंवागुरुसंभवंनिपत्यादि॥एवंवर्तमानोमनुष्ये १२
त्वेवंपरमपरिवारोकालेनवर्द्धमानोभवतीत्यादिना॥किंबहुनोक्तेनवा॥अलंपूर्ववत्कृत्यतो॥
ऽन्यदेवतायाविधेयंसाजपसाधनंवातत्सिद्धिस्थानंवानानानलाहुतानामथवातंपरमोक्त
मोगृह्यित्वायावद्राकेक्षीसंवीत्वातोचनमोहनस्यर्शनमानंतावत्सर्वंपूर्वंतत्सिद्धिस्थंकारयेत्

नाक्षीसेनसंवधूनानंकाचलनंतस्यसाङ्गाप्रसादिनंसिद्धिनामथविधिनाहुवनाअन्यच्चनस्य
साङ्गनाक्षीसेनसंवधूनं॥तेनकारलनंतस्यसाध्यापरमासिद्धपाजसिद्धिनामत्पविधिनाहुवनाअन्यच्च
नस्यसाध्यदायावनकजनासरागकृतिनादेवासराजादाक्षसंधानिपरमोपर्यंतसिद्धत्वापयित्वा॥वाधि
त्वेनसाजातनहुनानस्यवृद्धाहिपरमादेवगतिर्हेसलविधानाहुवनमनिहिवृद्धाहिपरिपू
र्णयतिनादासराजानंस्वाजावनकजनानांसंनपयकृतिनायथाविधिनामानसवशावनकजनानांस
वसूषसमनकानादेवतानिम्म॥सदेवदानावमतानिपूजासत्कारानिकरोतिनूतनंवधूसंयति
लहनासयासाध्यंतथागतंहेयानीपूजनंपूजासत्कारंकृत्वाहुमेतानिपूजासत्कारानिकरोतिनिम्म

दानानिदद्यादिउपवासमुपवसतिमहाद्वादशीचपूर्व्वाह्णेनिष्कारणेअपराह्णेश्रद्धिनान्यदिनेदानानिदद्यादितत्रकथङ्कृत्वा॥
कृतपूर्वमहाद्वादशीव्रतंश्रीमन्नारायणमहाराजानमनपदकृष्णिनगरवरेरुक्मवतीकृतेसत्ये
युगेधर्म्मगुप्तनृपसमुत्पन्नधर्म्मविलक्षाकश्चिन्महास्वाम्यनामिनामहाक्षीपतिवसतिहव
स्वानामतिकृमहाकरूनाविलमपत्न्याश्रीमन्महापतिमहाद्वादशीव्रतंकृत्वाद्वादश्यांपारणदिने २०
सत्यतिथ्यभ्यर्थकश्चिद्देवकोद्रुतिदापुत्रंश्रीमन्महाद्वादशिनंदेवनामवर्णितविनाश्रुत्वा
मायेत्यतिकृनिवेद्यानेहतिकमकृतिद्यामिधर्म्मकृत्यामिधयदामनकविहरविद्यतिनादर्श
मेपूजंश्रद्धयामिनात्यन्तदुःखायासंकृत्वधर्म्मकरुणेनाश्रयापरेतासमयनकनक्षिनात्मकन्दि

नासदंन॥सकलनसवस्त्रपत्निनाथवाविविहस्यायसर्वसखसाक्षनंदृत्वामहापतिसचात्मनेनि
नियोनिनं॥ब्रवंचयजिथानेदृतंश्रनेनदानफलेनमनसर्वसखाकेसनादासिदुःखसमुद्भु॥
दृतस्यात्॥श्रनेनकालजननदानपसिक्षयंपयदानंगछति॥ब्रवंवदविक्षनेकविवाप्यहिस
कास॥दूतालूत॥देवनाश्रयजिताथावद्भाहगवेत॥दूजिताहवति॥तदाश्रद्धावासकाचिकादेवताहि
त्यवृदलनंदंश्रंवंवाहिहिनंगमत्तालाजसमनज्ञालाविशुधिसूत्रसिनोविनामनिमहामुद्राहृदया
पलाजिताभक्तामासेनिविधातासंश्रीमहापतिसत्तानामनोत्यक्षविधिनाहिसिद्धयथाविधिकेत्यज्ञ
हिहिनंनाउपवासाखिलायो॥श्रत्रमहिव्यादद्याशसीसेवङ्कानउपूतपूसिसक्लाहविधिनि॥

अथ सप्तराजाप्रतिविबुद्धकृत्यान्वेष्याभ्यर्थनेसैन्यासिंघिनक्षत्रमन्त्रविषैवकानकुलद्वाभ्यां
शासनिपत्ययथाविधिनाकसौख्यादिषूनपूर्व्यनक्षत्रराजप्रतिपैनेसप्तशतगणनायाऽपवोमाक्षिप्त
यात्रयमर्दिव्यादयायथाविधिनाहिसिंख्यमौमहतायतिसप्तविधासाहीकृष्णवर्षीमहतिमहा
वृषश्रेष्ठयूदासपूजाम्कांक्षिन॥अनेकानिवसूनिकिंकाणिसप्तानीदानानिददातिस्म॥तकोनवा २१
नीमासानामसप्तयोत्सूराजान॥अहिसूयाःपोसादिकादर्शनियापसप्तयाशुक्लवर्णपुद्धसनयासप्त
खागनक्षतिं॥तनाक्षत्रीमहतावाह्मजसर्वकामीगमाअथसाजिनामाहतायतिसप्तसप्तनिविष्टनो॥महा
विधासाहीसर्वतथागतपूजिनाकक्रत्यायीयवद्रामनि॥सर्वथाव्यदाशकावानामिधामहतासप्तसप्त

सप्तेसाधकसूक्तामानदाऽमीसवमहाविधासाकवर्दत्वासंगमसप्तस्वरवनियचशायीनवरूपा
सवासप्तसानिनिनपसाजिस्यसप्तस्वस्यकि॥अथमनदवपूसैपविनति॥सवासप्तेसप्तधाख्यवनि॥एवं
किंमहतावाक्षतापथमस्विगोस्यादसप्तदायवोधिसप्तमहासप्तस्वसप्तमहायतिसप्तसप्तमहाविधा
साहीभप्तयत॥सवमासप्तनवमप्तयहवतिपयस्यवोकायकृष्णगतारुविध्यति॥सवंतभगताः
सप्तधानारुविध्यति॥सववोधिसप्तसप्तसिंगारुविध्यति॥सवंदवमनुष्यासाजासप्तवाक्षत
गृहपतिहिश्चसप्तसप्तिंवदिंतयुक्तं॥संमानिगारुविध्यति॥सवंदवासप्तसप्तलूनकिंनरसमः
हातगा॥सप्तस्वतारूपूरिगारुविध्यति॥समहतासप्तवस्तूवाचरणावामासवतप्रमदक॥सवव्याधी

विग्नोरुविष्णविनःसर्वस्यूपदंशपसलगुदःश्वास्यप्रश्वास्यनिःनस्यनदास्यास्यसर्वसाकविग्नारुविष्यनि
सर्वदर्वणाचास्यसतनसक्थिनंसक्थावसगुल्फौसंविक्षास्यतौ॥ॐमानिवान्यनवत्वाप्यिसाजिनाभा
साताविग्नामतामंतपदाहृदयानिसक्तसंक्थिनंसिथिलाकोष्यकरुगतानिकृत्वाक्षरयितव्यानिर्ग
सतनसक्थिनंचसनासिकलीव्यानिहावयितव्यानिस्वाध्यायतव्यानिहावरुतव्यानिवाक्षास्यनस २२
रुःस्यघ्रइनिःसिलंमंगलहावाविनश्यति॥तवस्वसस्यमरुत्यवपारुविष्यतिःस्वरुतमंत्रयदाः
सिक्षा॥सर्वकमरुशाशुहा॥ॐअरुतवसेवसवसपवसविशुद्धंहंहुंरुद्रस्याहा॥ॐअरुतविशाकिनिग
हसेसक्षतिहंहुंरुद्रस्याहा॥अयसाजिनाहृदयं॥ॐविनरविपसजयवसेअरुतविसजहुंरुद्रस्याहा

ॐरुरसंहरुद्रियवनविशुभनिहुंरुंलक्षरमालसवसेंरुद्रस्याहा॥ऽपहृदयविद्या॥ॐमनिम
निवर्शिनिमालोपनिसरुसकामीरुंद्रुद्रस्याहा॥हृदयविद्या॥अहाषःसववर्यवाभिसत्यशुभन्धे
अक्षस्यसंनियानेत्रकलसनिधाष्ठा॥ॐमानिभासनिमनयदानिमालापनिसराग्नीविद्यासाः
हीहृदयंकवचायनानिमनयदायनि॥सवत्रआगनधमसदायासदिनानिर्भरितरुमश्वर्षीग्रवजसि
खनपथनवाचनभासरुभवासरुपसदसनाव्रभरुत्यमनत्रद्रितिहातंवॐर्यंहुंगीवसवनभ
रु॥पीसंसिनाव्याकुत्रायतमरुसलरुर्यमहाविद्यासालेनिश्रयसाग्निनमहाभासंनिमहापवीसवा
ज्रस्यानामश्वयश्वयमविद्यतमरुर्लहीं॥ॐयैसवयापक्षयंकरिमहावसपसाकम॥महाराजान

तावद्गावस्तामुद्धरतावन्निसर्वमासकाङ्क्षा देवत्राविध्वंसनकरिष्यामि॥सर्वासनान्सर्विसम्प्रक्षालन
करिष्यामि॥सर्वमालापाशासमुच्छेदनकरिष्यामि॥मलमेनमुदाकरिष्यामि॥विषकाखाईचूर्णिकिसतप्रयागविद्वेषण
हिवासकाजैंक्षसर्वदुष्टविघ्नांविध्वंसकरिष्यामि॥सर्वदुष्टदोषिसत्वायीगजवलयुक्तांहिलनानावस
स्थानायसिंघासनकरिष्यामि॥मायानामहनसिंघनवावनपथनस्तोक्षायनशीवलमासक्षाहिपूक्ता २३
नांयसिंघासकृमीमत्ताभासनियावद्वेदोक्षिविसिपूरयसि॥ॐयंनस्तावाक्षजमस्तामसिसतामस्त
विद्यासाहीनकरिष्यन्तिहन्तुमत्॥सर्वदुष्टनस्तापूजाप्रापूजि॥तथावाहंक्षस्तोक्षजिनविविषा॥क्षमि
हिपूवपसिंघ्यामनवतीयीमस्तावाक्षजाविद्यासाक्षीसर्वविघनविनायकानाविध्वंसयितीयदाव

लगवंविलयहसितवदनमभिकनकस्तोस्तलसिंघपीठस्थंगत्रराजानामनक्षमालाहस्तंस्मय
क्रंवृषस्कंधिरुगवानपथमाहिसंवृद्धंयेनवाक्षिनष्णुस्तोपसंकांत॥सर्वदुष्टग्रहभूतवेतालप
हुतिलिकामस्तदानस्थहगवान्॥सर्वसत्वसंपरिवारेन॥तनैकमासकोटीनियुतशतसहस्रपरिवृते
नानारूपविरूपस्थहंसवलाकाकुलेवहविधिधमासविषयविकूवजाभिक्षूनांविशिष्टेकानानाप
हुरणदक्षीसहिनिमायागस्यवदुर्दशंपरिवार्यतस्थाय॥कुमारभूतः॥ततःसहगवानसर्विपरूप
हुसितवदनमनिकनकरत्नस्तस्तीमलोकस्थंसर्वसत्वाजोसहकुकुक्षीमालोक्यमाक्षीमहापरिसतीमा
हाविद्यासाहीमनसासफेकत्वा॥प्रवर्तयामासस्तमहापवित्रोत्यामस्तापरिसतायीमास्तोविः

घासाद्दीनऋनादवसवेतमासणायियीतादद्दशुःहणावैतत्रकैकस्यासनकपसिवासादनेकानिनिमित
क्तानिनियूनतसहनपसूषाणासनहुवइकवनोनसितखणपतेशुपासमगसासिमसलसिसलतुला
नामवैवार्चपथाहतमाक्षानिगहनिस्म॥मूढनरवधनरसवरकुमासाविधंसयनरकसथांविचेतुंके
खितस्वस्थग्रहविघ्नविनायकानीयेनहगवैनाविहथंकवैनिस्म॥तनकसवेदकुमासासनिखग २४
नाहिनिरिहीकृत्वाकचिद्धिक्षायदानिगहिनानि॥केचिद्यावदन्तसायीसेव्यक्षीवृद्धाथाकृतासुतम
हानहावाज्यन्यबीस्तीतथागतसमविवसाठिनिरिगामतापुसुखीदयूनस्मिन्नगसेविकसीकृतास्व
विवसिद्धिप्रसनकूयनिहानमसहावसपसाकमा॥यनसलाधैस्ला॥सैनस्ला॥समनान्यपसासीनाकृनि

नगोहगवानबमचकपवर्तिनीयथाअन्येवृहेसिनसवविघ्नविनायकीमासाचपाथियाविधंसयि
चाउनिर्गृघासगनऽनि॥अवंकृमनसावाक्कनेमनसावसवेगासहिपासानित्रप्राकाऽयैमनसापनिसला
मनसाविघ्नासाहस्मचनमानसवैघ्यसनरुपेसवेत्या॥पनिमाचम्यनिजासमयैपलीगुहानान्यबीदुकूवैः
नसा॥तस्मालहिमनसावाङ्मनसियमवान्नूत्मसबमासेगमनसिकासेगमनसिकलथा॥सवैकालैचसि
खित्वाकायकर्मगतीकृत्वाअसङ्गनया॥किमिनिपूवकाङ्कुपतीऽऽयन्यामहानगर्यासाहूवकदल
विकितनकनकवित्तपूषणपसोमा॥कनकनससान्यवमादर्शनयबकपूसूषय॥आहाफहहणावै
गाकुलेनेपूसूषेविविद्धायसोपयन्तिनि॥अथनेवबकपूसूषास्तंसाहसहफंपूर्वेरुक्तिखापव

नन्दिवर्धनं नृपतिं त्वाज्ञप्तिकाभिरक्षणं पूजयित्वा प्रस्थापयिष्यामः ॥ तदा सपुत्रवधूकः
श्रीमत्कापत्रिस्तामाह वित्तासाम्यीमनसास्मृतवान् ॥ लिखितोऽयं दीनारो वाक्षोवद्राक्षत्यनिसमा ॥ त
स्यमत्तासत्य स्यामहावनिसमाख्यः दित्तासाहायलावनज्ञसिरेकशासिहृता ॥ खगुंखगुंयथापीतु
मयाविकिगृह्णिनि ॥ तत्रस्त्रवहकपूषाश्रीमवनिश्चयसाहविस्तरेनासाश्चयास्त ॥ तत्तासाजाय २५
कुपितश्चुक्षितः कथयतिगृहथ लोपूषाश्रन्यूथिवीवदेशयक्षमुक्तानिष्कृति ॥ तत्रवहनियक्ष
ज्ञानसहमानिप्रतिवसतिविज्ञानानिक्तनिखोक्षोलयन ॥ ततःसपूषस्त्रेवधकपूषेलक्ष्मीयक्ष
मुक्तामीक्षसिना ॥ हसनंतस्यक्षासिनतस्मिन्तस्त्रीयक्षमहायांतत्रस्त्रियक्षा ॥ सर्वकुक्षसनहाभरूत्वा

हस्त्रीक्षाश्चयक्षविज्ञानपूषेरक्षयियक्षमक्षुतिं ॥ तंपश्चात्तिश्रस्त्वा महापतिसत्तामस्तावियात्तास्त्रश्रनस्त्रवं
नंपूषमेकत्तासीरूतदर्दीयमानविग्रहंदृष्ट्वावस्त्रवधूर्वक्षयक्षाश्चसनस्तादक्षसानास्त्यशस्त्रीसंक्षयती
स्त्वाश्चरथक्षयक्षाविस्मयमापन्नाश्चंपूषंदृष्ट्वावस्त्रिज्ञानेश्चरपस्त्वात्तिनायदक्षिणाकुनास्त्वा ॥ या
वत्स्त्रेवधकपूषेसाश्चनेश्चयैविक्तसेजासाचित्तानगाश्चयात्साजाप्रकुपितश्चग्रारूतकथयति ॥ यश्चर्वस्त्रवगः
नागश्चनंपूषंवज्ञानशीघ्राक्षिकाग्नतस्पपूषेस्त्रेवंधकपूषेवज्ञानशीघ्राक्षिका ॥ तमनतस्प्रक्षिक
नतास्त्रंमहापूस्त्रेसानद्रिस्तदक्किरूनायथास्पपूषा ॥ श्चस्तगत्रवंथितिनानिचवधनास्त्रिखस्त्रुवनं
स्त्रेवुनिनानिसाश्चाश्चनंतनासाजाविस्मितास्त्रस्तिनवधूनाकथयति ॥ अहोश्चरतिविस्मयमिदंपूषदृश्य

तत्किमत्रकासनैस्यादितिमविमर्क्ष्य॥अथसराजानंपूत्सवमाहयेवमादा॥किंत्वंहोपूत्सवज्ञानासि॥पूत्सवउ
वाच॥नाहंमहाराजकिंचिदपिजानामि॥अस्तिममगृहेपक्षिसहस्रमहाविद्यासाध्यासत्या॥तामिच्छाम्यहंदेवमहाप
रावा॥राजप्राह॥अरेकथ्यतांसैषामहाविद्यासुखेनाहमनयासर्वंवृत्तंसविस्तरं॥तासनिसर्वस
त्यानांसर्वइष्टस्वयमाचनि॥सर्वविद्यामहाराजाज्ञाकारमत्युपमावनि॥तोविनाकालंनैनांमहासंगनिसनि२दि
तंसाहाप्रहृष्टमानसेनमहापक्षिसहस्रमहाविद्यासाध्यीपूजितामानितांस्तदा॥तस्यवपूत्सवस्यपरव
र्षेकृत्वासैषकस्यजनपदस्यपूत्सल्लानगरेजेष्ठतायामाहिषकादलीप्रवेशेमहतावामर्दपूर्वमियंपत्सिद्धाग्रा
महाविद्यासाध्यीसर्वजनकविभूतिस्त्रीनानासादवस्यमियंमहाविद्याकोयंकष्टानादत्वाक

यिनत्या॥अरयेनुमहावाक्षसस्तक्षकनर्यंसूपसक्तनविधानेनमहाविद्यासाध्यीसिध्यिनत्या॥अथसम
हावाक्षसमरतिवपक्षसमनसाहगवनंपवमपुत्रकेनाहिप्रजाध्यपक्षमासर्व॥विदृहानविधानेनमंहत्वं
नियंमाहाविद्यासाध्यीसिध्यिनत्या॥हगवानाह॥भूतमहावाक्षसत्वामहंवक्षसवस्त्वानकंपयाम
नसत्वाभूरिविनाहतुमत्वनमंसकृत॥व्याघ्रिगानत्वमाक्षार्थमीनागहनमूहवं॥हविष्यतिवस्त्व
नींदासिदपत्तसहुनं॥उपवासंव्याघ्रिगोहत्वानक्षनपूज्यसंमत॥वृद्धपूजापलाहत्वाविमूढाबाधं
यनकरूनामदिपविहनमेव्याघ्रिसमंविना॥हिताभनयनाक्षविसर्वसत्वपूजिसा॥तास्वाबहुन
कपूत्रोकरूनुहिंसासिद्धनत्वा॥सविवक्षासिद्धाकृत्वधूपितानिवधूपसे॥तोमपुत्रकंकृत्वातंग्रामय

र्यासवकाविषविस्फुरंःसवनविषमवेंद्रानिकालयमूविवक्षणीविजयंहासमूणातियनविलंपरत्व
तिःदवलूणाभकर्लव्यानानारुद्रास्रुषितंःहिभवजधरंकुर्योदुक्तलनतत्यवंःचतुलंचमाताः
सानाचनुःपाश्वरिवसंलिषेनवाक्षहासीग्मसारेख्यक्षतियषूमहमसासूदमवसदासाम्यंचकस्य
मिनमालिखनःवेस्यषूवेतामर्भूमनमिन्द्रदेवसरेस्यसंःदासकृयसदातेस्वयजायतिमहामंतिःस्वाः १८
स्वसूहवेयसुरोदंगस्वसमालिखनःहोसायासूयसंपनलिखन्त्रियसहिनस्त्रासायामानिरुदभः
लिषेनवंदयनमःरुक्षायावृगृहुरुभमयाकुकूंस्वंयंजुवाःगुविष्णश्चमहाकासंरसकुवस्यंद
वनाःजस्यमचायियथापूवविधिनाकूंसमालिखेनुःसिषिखेवयनेनविधिदृछनेकमलभस्य

सनतंकल्छरुदंनस्यहविष्यनिःशासाग्रविनामनिंकर्यीयुजाज्यपत्रसंस्फुनंःपत्रस्यकशलंपाशंवकुंवा
यितश्चापत्रसंःकजपत्रसमालिखमूशलंपत्रसंस्फुनंःशंकिलिखनथापत्रंयथाविधिषुद्धस्यनंःशातात्र
मनयःसवेविल्फुलिंगसमाकूलाःपदवाश्वकलेवायथाविधिषुकिंकिंशाःनागम्बिलनिनाकार्यीः
मनिशासानवशार्वकानंयिसवंप्रयत्नेनहृदिवजयनिष्फुलाशाथेवानांवलंनिर्यीसाथवहुलिख
दुधाविद्यांधसान्मंसवेषांविद्यादवीसमालिखनाचन्द्रस्यासनक्षतोशाहुकुंगशाकूंलिखन्नः
षेशुषनुनांपूनसाहेरविष्यतीनिश्चंदिधिनालिख्यशाम्फदृछनकर्मणाःनस्मासवंपयनेनूभा
स्यस्फुनिमावलासवसिंहकलंकुनसगसीयावनासनंशापाप्तानिपत्रमंस्त्रनंस्यसंहवचनयथा

सेकास्मिन्यसमंसोख्यंपरकृतापसंसुखं॥ त्रयस्त्रिंशाद्देवनिकायास्तानंतेस्यसुतासयंजग्मुहीयमुक्त
स्यविसा॥सदेवसदासोस्यैवकल्पासिनशिष्टकृतसीमते॥अनियषुविशिष्टेषु नाकलोषुविशावसुः॥
जन्मतस्यमहात्मस्यविद्यासोद्यक्रमिष्यसि॥सर्ववृद्धेनगर्ह्यंहिपूज्यंस्कन्धःपरिक्लिना॥प्यसूर्यंसम
वाप्नोतियनिसत्साधोसनिकानसा॥नतद्वासा॥विधिनास्यर्गृहासाभ्यपाविना॥सुखंसयस्त्रिंसमालाह
विद्यनिमहायति॥वृधश्चवाधिसत्तान्यज्ञोस्यासयतिनिद्यस॥कायनसुखसंपनोवसेनमहतहवे
नायथनदेजिनाद्रोकेवकवर्हिहविद्यति॥स्रोम्यसनंनरदेवानांनासनंदसूर्यतसा॥हविद्यास्यश्चिरे
नासायस्यविद्यासहाखिना॥नाभात्म्यनिशस्त्रनठाविषेन्यनागिनानाकासमनवास्यरसेगकुतियो

पक्का॥दसनास्यगनिश्चेवसवस्यसदवसवनाकूतगहविवादाश्चउडुकानिहयैतथा॥सगव्याग्रहयानाम
व्याधयश्चसदासत्मा॥तुसवनहनविद्यातियषोविद्यासहाखिना॥सवर्षीसवनासेस्तुणूवक्ष्मिः
नत्वनाप्रजनियाहविद्यनिसवसत्खोलमाहतनि॥ १ ॥अरायिमहापतिससंयमहाविद्या-
लाभृथमकस्यसमाक॥ ॥अरक्षनाविद्याधरक्षाविमनकस्यैव्याख्योमिसवसखा
नूकूपयायनरक्षाविमनेनमहासिधिरविद्यति॥यनयतकुरक्षफवस्यवृक्षनसंगायनिन
सेवेवसवगहनिवासनं॥सनक्षमानूकूलवकमसंकसङ्कदनं॥हुकंकृत्वधितेवसवसहुग
नैकनं॥इद्याक्षनंरसिधितेवकावदासूना॥वूनमेनाकनंवेवविष्णुकंनथायसेसवनस्यप्रमाण्यनि

रक्षाधस्यतनयत्वीनिसाविषयीनयाविधासमनिकृमनोपस्वेकादासूनायधियत्यामिनामलहयान
सवनपसर्यंयानिपतिससासापनक्रिना॥वृक्षरक्षानिसवल्लेकाधिस्त्वाधसरक्षात्सकानिपत्रेके
वृक्षन्वहोवकाचमहापनयाअन्यवबहविभस्यादेवानागमहृद्विका॥रक्षाकूर्वंनिनत्यम
रक्षियन्यकस्यनित्यस॥अस्याःमुनतमानेजविघ्नोलाक्षनलोलम॥निरधाकुवनिसवनक्ष्ये ३०
वमलवविनाइस्यप्राइस्कनायकउपसर्ज्जायचदासूना॥कायेरक्षामहासाशेधमस्कोसाजय
क्षनाअन्यवबहविभलक्षागजसूकविधिकाङ्नयदासूनायचगकसनमासूनूजोम्यजो
मनुष्यानीविनासार्धंहिंसेकाभिसदासूजा॥सवनंविनत्यनिरक्षायनमहावला॥अनयादून

रक्षनुवध्यप्राणिविमुच्यते॥यद्विग्रकूकालपालनानिनवाधियमास्यी॥आयूरुस्यविवधने
वनिससासेखनादधि॥पत्रिलक्षीलायूषायमुसफाहंमनत्रवा॥यावनलिखनमानेनसजीव
निनसंसय॥अथवनमानंडाकूनाक्षाविमानेन॥सवनस्यक्रिपाप्राणिसखंजीवनिकृपया॥अ
थवाविंडाहमाणिकाठिनियूतनानिनवात्रुयनिसनिकायदवा॥सवैतेःसार्द्धंरक्षांकूवनिनित्यः
सोमा॥समनाःस्यिवक्षाविवृमदव्यसा॥यमवमानिहदवसवदवामहावस॥यूयंहदामहावी
लहोलानिवसयूनिका॥याक्षतेषाकिंकाक्षेवकानियागनेस्यसा॥श्रीरधिवमहादविवंशमनव
सतस्यनिप॥संघिनियूष्यदनिचनथेवैकऊढाधिव॥धन्याग्रामहागलक्षांकूलवनिनिस॥षश

नीपनजननीनीरगस्त्रानविवर्हनं॥तस्यैमहतिवास्यैयावज्जीवंरुविष्यति॥नसानाज्ञयदानिर्द
यूद्धसमनरैस्सदा॥अनयावत्सदाहानिदेवताधननिश्चिता॥अथयापत्रिनष्ठानुस्त्रिवनादेवमंद्य
न॥नथमनविशोकृतिवाक्षिस्त्रामहृद्विका॥यशंचवर्हनंनस्यपन्यनायूविवर्हन॥धनक्षना
समहिचरुविष्यतिनसंशय॥सूर्यस्याग्निमभवीसूर्यंवपतिवृक्ष्न॥अथ्यःसवसक्रुनीस्व २१
कृतगनैलग्यि॥सीगमवनमानस्यजयारुवतिनिर्यंस॥विधायासाध्यमानायाग्नियंसक्षनूर्ल्सां॥
सूर्यंसूर्यंसोधयनेविधीविघ्नास्यनरुविष्यति॥सिध्यनेसवकृत्यावपविथस्वमंद्रे॥क्षिप्रंवसम
यक्षुसरुवसवनजानिषूवैष्यसिकारुवनिर्यंजिनानीगुरुधासने॥सवनीगस्संपूर्नेसवसिधिः

मनास्यं॥अनयासिखिनमानेनस्वस्यक्षीसन्धनि॥सूर्यंकासकायाकृत्वारुवस्यनृपस्याय
नं॥विवादकरुरुचैवविग्रहयसमदास्त्रो॥सवरुपविनिमक्कोगिनाकैववर्नय था॥निर्यंजा
निस्सोहानिजानोजाक्षीनसंसय॥राजानावसमरुस्यमन॥पूसमहाजनाःसामास्यचरुवन्दि
लीसावृद्धिसोकसीमनाःसवर्षावपियाहोनियदवायचमानूषा॥सक्षानस्यकसिष्यनिरुव
सागानसंशय॥अनमनयदासिद्धाःसैन्यकैवृद्धनरुक्षिता॥नमोवृद्धाय॥नमोबमाय॥नमःसैन्य
या॥नमोरुगवरुमाक्षनूनियमाहाकालनिकायगथागताया॥अरहैनसैन्यकैवूभय॥नन
सकानां॥सैन्यकैवूभनीःस्ववनैतानमस्कृतेवूषभासनदृष्ठय॥अरहमिदानीयवक्षानिस्व

सत्त्वानुकंपया ॥ ॐ नीवि घासरक्षा रक्षा वसापसाक्षमा ॥ यस्त्रीरक्षि तमाता पासूनि नीवज मयासने
मालाच मालकाया वगमा कासर्वविनीयको ॥ वि घ्रावसनि यकंचित नरक्षनीवि स्त्रीगता ॥ ॐगंगसि
मिलिरगिलिनिरगिसिवनिगुणवनिलाकासविमुहासवपापविगतासाकालागमनतसोसाका
सक्विवासिनि हसितशिखलो मतिसूकषवित ॥ प्रासिधसेसकलासुवनासवनलोसोसरिनासा ३२
नृत्यनासरनागनोपस्यूत्यनोनमस्सवषावृक्षनीहसितनजसो ॥ वहुसवहुहाकावनिसूसक्षनिसूप
हासदसोसूदानावसवसोकगवनि सूहदवनिरुद्रसरुद्र विमसोमयरुद्रावशिरपचनुस्तु
वजवणुमरुद्गणयासिगक्षसिनोसिमातगिवक्षसि सूमनियूक्षसिगवलिगमवसिसैकसि

ड्रामरुद्दादानिष्ठि सादिहादहनिदारुनासुवधिसाधनिहनरसवसकृमिमसवसत्त्वानाक्ष
दहरसवरक्षानहतपतपिसावदाकिनीनामनृत्यास्थपचरुदयविश्वंभयंकरीविनं सवरूथग
णाक्षचनाभयसवपापानिमहगवनिलक्षरसवसत्त्वानाचसवनसवदासुवरुप्यापडुवस्य ॥ स
वरूथपदक्षानीवधनंकुलरसवकिल्विषनासनि ॥ मत्यूदनुनिवासनि ॥ माकंद्रुमानिनि ॥ मक्षामाः
निनिचसोविष्टिरनिष्टिरनिष्टिरनिनिनितुदाद्यासिनिवीसिनिसिसिनिसिधसेपवससमयावसु
सिमातरोवक्षसिसूवसिसमनिपूक्षसिगवसिगमसिवाकसिदमिष्ठिदामिष्ठिदहनिदाह
नियकनिपावनिमदमिससलोसचरंहरिणमक्षाकृथविदासिनिमहिसिमहिसैमाहा

महिरमहागदहंजमकमल्लिनिदानवक्रवक्रवाक्किनिठसरहासिनिसवसिग्रवसिसवव्याधि
हासिनिन्दनिश्चूतिवनिवनिरमहाचूतिनिस्लिम्बरधसिनिशोकदहनिनेशोकाशोककसिनेभक्त
कव्यवशोकनिवनयसगुणासंषरखगवकनिगूसचिनामनिमकूष्मतविद्याधसिनिलक्षरमासवनसर्व
ज्ञानगतसवरक्रुद्धयस्या॥सवमनक्षामनूथहृद्यस्या॥सवव्याधिस्या॥वज्रवज्रवनिवज्रपानिधसंहरसिरकि ३३
सिरनिसिरकिसिरसिसिरवसरवरद॥सवनज्रयसक्षस्यहा॥सवपापरक्षिकासिनिस्याहा॥सवव्याधिहासनि
स्याहा॥सर्वसनिस्याहा॥सवसकुनहृद्यहसनिस्याहा॥स्यलिवरुवकुस्याहा॥ममसवसखानावश्यस्याहा॥ॐभु
वःस्याहा॥ॐसानिकसिस्याहा॥ॐमनिस्याहा॥वसवदनिस्याहा॥पूषिकसिस्याहा॥ॐहयग्रीवनिकमलविम

सस्याहा॥ॐसवनथगतमूर्छस्याहा॥ॐभुसिहासौनिस्याहा॥ॐभुॐभुसिरवज्रवनिसवनथगतहृदयपूसनि
श्रायूसंक्षसनिवसवसवसवनिज्रयविद्यहूंरुद्रस्याहा॥ॐमनिधनिवज्रनिमाहापनिससंहूंरुद्रस्याहा
यसकस्यचिमहावज्रनश्रनथगतमूर्छाविद्यामनपद्मक्षसिन्धसक्षाकुमारुपैधनिहानंपसिहरं
फतिपासनंजांनिसस्कापनंदनुपसिहासंजमंनेपसिहासनंविघनासनंकुमरवेहा॥नस्यपसिक्षीनायुषः
पूनसेवायूविहिनं॥सविससूषंवज्रिवनिसंहनिसेपन्नसरवनिउच्चासनमांनवावज्रयमाज्ञनेनवाश्रक्ष
समस्तमहाव्याधिस्यपसिम्बनं॥सवसोगक्षसस्यवज्रायनि॥दिव्यस्यायवमाज्ञनमानेनपसमंगछ
निाादनेदिनेस्याक्षायंकूथीनमहाव्याहरवनि॥ॐआजावसवीर्यवसैधनिहानसंघनाहवनि॥सवपाप

कमवस्त्रनानिचास्यानिवगवदनियानिनीस्वशुर्वेवासपरिक्षर्यंगाकृतिः॥सववधवाधिस्त्रदवनाग
क्षगाभवास्तगस्तूष्किन्नसादिनिचास्यंउाजीवस्विर्य्यवस्कायपक्षेप्यतिः॥महापिनिवद्रुसाहुविष्य
निजमहावाक्यनरूयैमाहाविद्यासनपदस्क्षोनिर्य्यकृष्णानिगानानोमपिवमगपक्षिभंयषीक
वृपुत्रनिपतिष्यतिः॥सवनजरवर्दिकाहविष्यतिः॥अनुलसायास्त्यक्षंवाक्षो॥कःपूनवाद्यायरूमी ३४
माहापतिसराक्षरनिद्रमहः॥कूलपूगावाकूलदृहितावाहिक्षनिवाडपागकावाडपासिकावा
राजावाराजपूगोराजमाख्यावात्राक्षजावाक्षतियावानदुन्यावाय॥कश्चिसकृत्यक्षरयिष्यतिः॥त्र्यं
चमरूत्याशुयाशेसवनक्षगनस्यिष्यतिः॥सिवापयिष्यतिः॥क्षरयिष्यतिः॥वावयिनिनीवनमनसाह

वायिष्यतिः॥पसेरुस्यविरुरेनसंपकास्यिष्यतिः॥तस्यमहावाक्षनरूयैकासमसनानिसुवथपनिकं
क्षिनयतिः॥नावास्यकायमसाक्षधपरुविष्यतिः॥नावास्यशलिरेश्वरिनविषवेसंक्षंनगसंनकाष
दनकिसनसूनिवगाठनमनकमनस्वृपियागानवागतूसंनिजसोनसिसावर्किवा॥ब्रकाहिकंगाहि
कंस्याहिकंवातुर्थकंसकाहिकंवाठसानकमिष्यतिः॥सस्तत्रवेसूर्यस्वाम्निनास्त्रपिनिसमहि
त्रवंविवृध्यनः॥माहापतिनिवानसाहेहविष्यतिः॥ज्रस्वंसहधमनमहदस्यर्य्यिक्षयिगकृतिः॥य
त्यनियपद्यनतत्रनजातीजातीजातिकस्मसाहविष्यतिः॥सवसलनावयियारुवतिः॥वधनियप
पूगसाहविष्यतिः॥सर्वनसकनिर्य्यकलयानिगनिगहनपगोपपर्किरयस्वपसिमकाहविष्यतिः॥यथाक्त

मनुष्यैस्तवस्तानीतथारसयावहस्तकरोहविष्यति॥यथाचंदमनुष्यैरमरूपनपहरवक्षसवैस्ता
नाश्रकायपक्षादयति॥नभधमानरूपनसवस्वविलसंतानानीपक्षादयति॥सवदृथपक्षतो
क्षसरूपनपनविज्ञवामादापसमासदाकिनिगहविपनविनायकादय॥सवस्यमहापतिस्तो
महाविद्यासाक्षा॥यहावनशक्तविरुठनाकर्तुमूपर्संकल्पनाश्रयक्षामियैमहाविद्यासाक्षीस ३५
मर्लिया॥तनरूक्षसवदृथविर्लीविद्यधस्यश्रहात्रवनविक्षयाहवति॥श्रस्यायवानूहावनयः
दनमहापतिसेतायामहाविद्यासाक्षनवास्यनसरूहयैरुविष्यति॥श्रनतिकमनियावसरुविष्यतिः
सवशरूगनेरविसाजमहाराजमहाहैवाक्षनगरूहपतिहिक्षानसावध्याक्षपिवहकपसूषेसरि

तान्यपिसम्भानिखसुखदुःखकृतिः॥यथायासमयानिवविशाय॑तः॥तसिंवसमयसववनाश्रस्याम्
रिवरुविष्यति॥मरुत्यस्यसमनिवसंरुविष्यति॥लक्षापंनयसमंक्षतनपपितृंयापनासनं॥श्रीकसं
धाकरंचापिसवस्तुनविवमनं॥सवमंगरकरीक्षवंसवोमगासनासनी॥दस्यप्रदर्शनिकापिदस्य
प्रस्यविनासनि॥सनिपूसथापरासक्षाविषयंदिमक्षावसा॥श्रनवीकासदृशिनिर्लीमकतिनरुक्षनाम॥स
वकामावसरुतसंवमस्यवचनंतथा॥यथउस्यथमापन्नत्रतीविद्यासनसेना॥पक्षमनसरुत्रगापूर्णोम
नंयानमरुलीं॥कमनामनसावानायकृतंपूवगमस॥श्रनुरुवरुविसाकिविलसर्वक्षपयिष्यति॥
समसक्षासनाचेवडाहनासिषनादपि॥पठनाक्षासनाचवश्रपनास्यसंदसनाकाहविष्यतिनिर्विसेना

सास्त्रवषमगतिगतोऽत्रवषमस्सेषाकषायाग्रहनिसंशयो॥स्वंनस्सर्वकर्मानिमनसायद्यद्दिष्टि
नं॥सवस्त्यूहयवेषानानंनस्यहविद्यहि॥सागाग्निस्तूदकंचवविद्यहानस्कसोधिवा॥यूहसं
गमकस्तहंक्षिनोयचदास्ना॥स्वनेपस्यथायिविनायास्क्षणायाविद्यंयंपस्मीसिः ३६
धीसववृहहिदसिना॥किंतिमानानहिदनिकाभिसंहारपूस्यका॥सवधूवस्कासवविधोप
यागयना॥यानिवर्कनिकमानिस्वयसाथपसिद्धया॥सिद्धनयन्नस्कानिविधकानानसंसय
नमःस्वनथागनक्षयस्यपिनिर्थंनिदसस्हिक्षु॥उंमनिवगहुयमास्सन्मविद्यासिनिक

स्सवगऊनतक्षरमनगसीसैसवसत्व्यवऊरवजगहुत्तस्यरस्वमास्हवनानिहूंरुद्रस्मरु
स्याहा॥वूधमेनिनध्यागत्रवजकंस्याधिष्ठिकुसवमाकवसनान्यपनयस्महा॥नदिदानिंपव
स्कानिस्सतुलानींविकिन्सनं॥चतुस्मंमनुस्कंकृत्यानमामयस्मधिनं॥पकसंगिक
नृनाविनयमदलंहगुहं॥चुकुलःपूनकृष्णास्त्वस्तापयहिधिनावूधा॥पूष्यान्यंकीसेनत्रधूपय
हूयमूनमं॥वसिकंमकूंचितमहासाहवमाहुनिपूववगाभवूणाऽर्घाऽनविधानहा॥वनम
स्कीसिकास्त्यथा॥स्वाव्यपद्वहुकाहास्तापयित्वाश्वकुलंयकाकृविवस्कसमादहा॥शुहगाधा
नसिकांगंपवस्तयमव्यमनुसं॥पूवाम्स्वंनिबंधेनमनोविद्यास्ट्राहसेना॥सकृत्मऊकयाव

स्यसक्षींकुर्यीर्कवक्षन॥अकुलस्यननोस्त्रायवालाभ्यकविंसति॥उदासेदिमौंविद्यासवलोणा
पक्षनय॥क्रूयप्रसक्वासावेवतिकूर्कसनचिनं॥पक्षस्त्रिवदयमस्विसिपूर्यंयक्षविधि॥कं
स्त्रवंदक्षिनेयास्यपक्तिनसकप्रवंतु॥पक्तिमायानुसकेवउलसायोनक्षादिसि॥अधउद्ध कस
केवदूकातक्काहविद्यनि॥प्रवंदूनेद्विजश्चक्षसवर्॥खपमस्यनेप्रर्षासक्कासमाख्यातानाक्ष २१
सिंहुनकायिना॥भास्त्रस्यापसाकस्त्रिद्रक्काविद्यानिक्षनुका॥ननस्यनस्त्रनज्ञसानसाग्रानचाधि
यजातुविद्यागलावा॥नक्षाधियकुस्यहिसेपयालाहवहियालाविनविलसेनति॥स्यभाषितस्य
वसयस्मिसाजाकसिद्यनेपूक्षस्त्रमेतवेन॥कथयिद्यनंदवपुसेहिगकूखनिर्वनमदनस्क

पूसेकसिद्यनि॥ननविमानेस्तवहूपकालेमहद्विकायानिस्त्रालयेंमुहे॥प्रवैक्षमानूमस्यकसाक्ष
सेंसंपूजनाहूतसदाहविद्यनि॥वज्रपानिस्त्रयक्षदाक्रन्द्रचैवसविपनि॥हासीनीपाश्चिकंस्त्रव
लोकपासमहधिका॥चूडस्योसनक्षत्रायमहालमदासूना॥तेवसवेमरुतामगदेवग्रासयस्त्र
ऋस्त्रागलूजागीधवाक्षिन्नस्त्रावमहाधिका॥निद्यानूवहासूर्यक्षयस्त्रयविद्यामहावला॥लिखितौंध
वासयस्त्राश्रुवाक्षावक्षमहधिका॥महधिस्फूतपूजोसंयदंचाधिनित्यसंज्ञनि॥ ॥श्रार्यमनः
महापतिसलायामहाविद्यास्त्रविद्याधलस्यलक्षीविधानाकस्यःसमाधं॥०❀०॥ॐनमोह
गवस्त्रश्रार्यमहास्त्राहूयमडने॥प्रवैनद्यास्तेमकस्यसमयहगावासाजाहूविहूलनिसम॥प्रध

नरसिंहिका॥अहिसंकुलाश्रयकलानाकुमलानाकुमलकागनकुमलामाख्यानश्रयपाश्रयाधश्री
दासिदासकनकसथक्षकपसिवालकाहलैसंधिथिना॥समनसत्ववैसालिजनपदयाहिक्षुहि
क्षुपाशकापसिकाहि॥हस्तासंविग्नाःसैहकुलमकूपजालाडहिमूरकायकंदनवूधर्तनसंघनम
स्यनि॥यकचितमहावाक्षनगृहपनयावूर्छासनेनाहियसन्नाहवाथकलावाक्षनगृहपनयोवन्ना
जमस्यनि॥कचितयूनःसंकचिसूनःसाकपालानमस्यनि॥कचिसूनमहत्सामानिरुदपूर्णह
ङ्हासितिचंद्रसूर्यग्रहनक्षत्रयवृत्तवनवल्लीषमिदंसविद्युत्ससाद्रदनजागकूपदेयस्कानान्य
थिलमस्यनि॥कथंनामेतत्साहयीमर्वसूपा दूपदवनाहयस्कानासंसिम्यना॥अथखसूहवांगस्कु

अस्पपसत्यहिसंस्कालनकाषीनाथथास्पनस्यहिसंकारेसंस्कुनेननिसादुमनसासादुमसाकथाकुंस्य
सेनविस्तायसदेवमानूषासूसंसाकंपसादसनिपातयामास॥अथवकासक्षापतिवक्षकाथीकाथः
देवानामिन्द्रोदवाश्चतयानिंमथत्वासोमकासाजानश्चाकुमतासाजकाथिकाश्चदेवा॥अथविंसत्रिहि
श्चमहायक्षसेनापतयाहाहिंगश्चमहायक्षनम्नाहासिनिवसपूतिकाःपसिवासाश्चतिकात्ववृत्तिश्चति
कांकायांसाकेकवसंगृधकूटपर्वतस्यकनवसूनहावनउद्यासनावहासनावकास्यायनहावोंकेना
पसंकाता॥उपसंकल्यहावनेःयादागिसत्तावदिस्वायकावाहोकस्यसोकेकपदनहावंतगाथहिनुस्कू
दकंकाश्चनंनिहासपूर्णचन्द्रपहास्यसा॥तीवंग्रवनदीसत्तानीनामाकश्चहिं॥सिंहवासननिकांत

मर्त्यलोकगमनं॥ एवमेवास्वनस्यनिर्देशोम्यूनदश्यत्वं॥ वधावाविनश्येत्वाभिनक्षत्रहिपूसक्तः
मक्षुसावकस्यैवस्यलक्षणे॥ समर्तकृतंः शोकः सदेवकाकृत्वान्निनोऽसनमागत॥ मनूष्यानोक्तिनाथायस
क्षाकासउपस्थित॥ मोक्षसाहसमपमर्दूनंसूतंसर्ववृद्धे॥ एकास्तिंः श्रावकवाउपर्यिनस्तीमावधनमूर्छि
सनमक्षुपूसुषावीसनमक्षुपूसुषाकिम॥ कूताऽसिन्नमस्यामिधमराजन्नमक्षुकाथखसहगावा-मक्षु ४०
रूबूरोवेनाधिवास्यवतुरोमसासाजानमामनयामास॥ नेननमहासाऽन्त्रनिसूपैयघूष्यस्यलिषदा
समयसिषदंविहृंयिनयमन्यत॥ नक्षस्यहृनाः ऊनोक्तिमानूष्यशोकवूढोस्यादाधमस्याख्यानताचतैय
सूयनिधनताच॥ ऊदमास्मिंवीरमवसाप्यवूभरगावनोसाकउपपंनो॥ यहाकूवूभाक्षभृतं॥ साक्षकाश्चय

मर्त्यलोकगमनसूत्रान्यसापदसंगहार्निगदंदेवनिकायाश्चनसंश्चनलेदेवनिकायउत्पद्यन्त॥ राजानो
यिरुवनिचेतुरङ्गिनश्चतुर्द्वीपस्यसाम्राज्यकारिन॥ समुदपर्यंतनमहापृथिवीमनुशेनधर्मनसाक्षः
कायनिः॥ क्षावपूनसहसंरुवनि॥ शूरानांवीरानांवरागसूपीडांमहानंनवसेवगाक्षसिंधंपलसेन्यप
मर्दकानांसकलनसमाक्षागतानांनयूथाकमलासूकविक्षारेनविहरनामवसूवाजमनसिंनिमसाक
नोत्यहिरुवश्यनि॥ रथदेशवनमहासाजारत्यूक्ष्मासनादकासमूहरासंगंकेलादक्षिणंशानूमहुसं
पृथिव्यांपनिक्षापयनरुगवांक्षनांजलिकृत्यारुगवनेनमासमानोरुवनमनदवोवना॥ सविरुदत्रहम
वनस्माकमदासाप्तिमूहस्कानानिरुवनानिनगासुधानविमानहस्यकूटागासानिनियूहुकासनगवाक्षस

रसविसविषविषविनपट्टासविविनघण्टावानसमूलाजास्यतिक्षिकानिधूपघटिकनिधूपिनानी
पूष्पावकिंशुनिधूपंवयनासिनसकुसपासिदृनाासंपूर्णेपक्वहिंकामरुसंसविनासमन्वंगि
कृनाविहरायाकेखासस्माकंकुलनहृदवंयमकीनांमासंविहासविहासिनांविहसनापवेद्रासमना
दसदिनाअन्नपानहोजनानिमागयतिाप्रवसायमानाःस्त्रीपूसूषदासकादासिकानांजानगरुथानांनि ६१
यीस्यानिगतानांसर्पिवपानिनांमाजीहसतिविक्रेष्यतिविधूयतिमासंयतिकिंविनाअपसोमयतिा
नवयेहदनरुगवनारनिकवनुनीमतासाक्षानंपूसनाास्यकुस्यकानांपवेदीलूपलक्षनंसन्द्रनंथिव्यामाप्य
स्यपतिप्रदायागहोरुविष्यतिाकुरुकुसमकासाजस्योदासंचैस्यपतिमीकरीष्याासंकुसंचकुरुकुनस्य

महाराजस्यनाम्नानानागंधधूपाधपयितव्याापूष्पावकिंशुकनिंकुंकुमादीपाश्चदीपयमानेाातत्रचैत्यपतिमां
पूजांकरिष्यतिामदीयायाहुदनरुंवन्यस्त्रिषदायक्षंदक्षपूर्वदिनस्यकृदंसंपूपलक्षनांकुसतिनगरेहिक्षू
पलयंचविक्रीयनाानिदाअविशनंनस्यनशावाप्यजायतंजुदंसंप्रक्षनंनिर्यनकृतान्यनुभावतिाासो
दर्षमायातिवपनंकुनंनसदाासरनंतयज्ञान्यक्रिलाकुनाथशाक्षहिमाास्यायथर्दसिकुसूसिकुस
सौाअमसेअसेअनहवसेमहावसेअकुसकुसगतिसेअमसेअखनेमखनेखखःखखनेखसंढःखसं
गरुलविगसेाामिमिगिसेकिंकिंकिंखनिमिगस्यदाासिंहुंनुमनपद्रास्यादाासमसवसत्वानाश्चस्य
स्यतुवैश्रवनस्यमहाराजस्यनाम्नावसेनेस्वक्षिपस्यनवस्यादाासथवनसाधूमहाराजास्यूकुम्यस्य

नादकासमर्कलासंगकुचादक्षिनजानुनंदस्यधिपतिकापयनलावीक्ष्नीजसिक्तचारुगवतमनंदवावत्॥अस्यस्यतिषदाकंदनरुगावनमनंदवावत्॥अस्यस्यतिषदाकंदनरुगावनगंधर्वमादनहीनस्यऊर्द्धंसंस्थसक्षा
नीनृत्यनाशयंतंवाधिकृषनानिद्रियायंताअस्यैःसत्यवादिवरुसनेकूपंतेपून॥रुक्षूयंतसकनै
कांडलस्याविसंतेसदा॥डंभिषंतेवक्षुरुग्यंतेवपसौंमुखा॥नंतुमंतुपदान्यक्तिसाकनाथंनाहिमा॥स्यास्यथुंखखखमःखसनेखसंतेः ४२
स्यास्यथदा॥अखनखविनद्धःवक्षवसासवसंदवपसेवखवषनै॥अखिनेःनखिनेरुसेकागरुडसे
वनवसकंहिनित्या॥मृत्युंसर्वसत्वानाकंःसर्वग्रहस्यधनताकस्यमहाराजस्यनाम्नावसेनेस्वर्यी
षियंतनवस्थाता॥अथविस्टंकामहाराजास्यूर्ध्वमासनादकासमलिसासगंकुचादक्षिनजानुनंद

राजास्यकुष्मसनादकासमूलिसासंगकृत्वदक्षिनजानुमज्जुंपृथिव्यांनिधायपयनरुगवानमनन्तु
वावनाम्नस्तमस्यशिषदारुदनरुगवन्नागास्पर्शूगरुडगृहिनस्यक्रन्दनेसूपसङ्गनैदिकनस्यस
नेचाधिनातरेगानमवच॥स्निग्धनहनसासास्यस्यनवपूनःपूनःवर्तीस्वनेसुसावपनक्ष
वननक्षाःपूननेखविदर्भनिमहिविभनिसोदकाःतनत्रपदावस्किसाकनोथगृनाहिम॥सायथ ४३
दःकगमःक्रकमनिःकमस्यक्रुकसःक्रकगसःकुगुसकुमसकुमस्कुमःअगसेःनगसेसमगसे
ककुगाकहुमःअसुकेअसुगकेःकससेःकेमिसेधितेअगासूनित्यादा॥ममसवसत्वानाकविसू
पाङ्क्स्यमहासाजस्यनाम्नावसेनेचयीधिपनवस्मदा॥अथरुगवीस्नायनेसवत्सावस्यपसिषद

पूसनसिंहनादेनदनि॥दसवसेसमन्वागानोहंवतुवत्सादाधर्षचूदासमावरुसस्यमक्षिंहनादे
नदाभिवक्षुचक्रुंपुवनियाभि॥मासानिर्ऋतेत्रकनससन्यवसवोहन॥सक्षायेसर्वसत्वानोसव
सवविद्यीमूनाहिम॥सायथदे॥मसंसारवज्रवनःवस्वनःवसनिधाषःशुसेसुसवरेःवज्रवर्ज्ग
मःवज्रघसेःसुक्रुंहुःवसासेःविसर्जविषसवसागप्राक्ष॥असहधाधर्मयूकादसिविषूक्सात
स्यस्नुममसवसत्वानाकेनथागनवसेनस्यायाधिपनवस्मदा॥वृहस्यवेवनेकृत्वासकणा
सायकुर्दनेउनस्महीनसंविग्नभूस्नासु॥पाङ्क्तीकृताःसिक्थालकृगानाम्रुविक्षिप्ताविसर्पीस
सिकृता॥पराय्यनदसदिङ्गामहानागमृदिस्यन॥नहिदस्यामहाराजक्रिमुकुंसमृदाहसेन

अरुणविशालविशालहालारुणमदनि॥यत्वामरुसन्निरूक्तानिरुक्तावद्ध्रौक्षिणं॥यथापठसिलोवक्रिलसी
वानेत्रयाग्निन॥रूक्षसस्तमाविर्शीलोनमनमकाक्षिना॥यावद्वैनाक्षिनत्यनवृधवक्षंसुरुक्षिणं॥क
स्यानवक्षसापनजंघवृनारुविद्यनि॥सन्निपज्जारुयिक्षातुरुहिक्षिनसुषीपान॥घृतमदनसंयू
कपक्षिकव्यहनाक्षनं॥रु०ऽ६ऽरुतुदिक्षुकाचवत्नोदकं॥यदिक्षिपनमूचयूसिदंत्रुक्षासुरुक्षी ४४
नं॥रुवनुठसिलासवयक्षत्रेघृतसंधान॥क्षेनंचनसक्षानियक्षदत्तुननक्षिना॥रुषीदक्षिनेक्षयम
हागलुरुविद्यनि॥क्षिनरूनारुविद्यैनियक्षसाहानवीक्षिना॥अतुरुवनिसाजमनिन्नगाहनिकुम्बन॥
निदक्षनंनसयूयनिकूवलस्यस्त्रीन॥जाम्भसनवनसयूक्षिरूनसंधासमागमंश्रन्नयानेनसरिक

जायनेयक्षमसुरे॥महारुयमदनंसुनंयायक्षनानूलिन॥तस्यवजावसंकुठामूर्द्धनिस्नाढ्यिवनि॥
कर्कगक्षुलक्षालेनजिह्वानस्यलक्ष्यति॥नीक्षनवास्यमक्षनकर्णनासीवक्ष्यनि॥यपाढ्यनिकू
कनक्षुलक्षालेनमस्तकं॥रुमक्षुलक्षिलेनहृदयंवास्यपीड्यन॥मुखनःश्रवनवास्यपूयमूत्रक्षुमि
निनं॥विद्यापोक्षनदक्षुनसदासंसारगमिन॥तनेवसंनरिष्यतिसंसारेचकुमक्षुरे॥स्त्रियोविद्या
मक्षाराजनःसमागम्यवक्षुदिनं॥यमस्तन्नाहसन्नर्हनिषक्षूरुहृदयिष्ठका॥यनलाक्षुस्यपूवायांदक्षिणः
नविस्तरुक॥पश्चिमनविलूपाक्षःकूवलस्त्रालनादिनं॥साक्षंसमागतानांहिक्षैरनांतेजसीस्त्रिया
जनलोक्षनदाशमक्षासर्वक्षहिसन्नक्ष॥वज्रासनेनिषद्यहविमानेवक्रनिमिनानलोवक्षामहावक्ष

पाङ्क्तिस्कानमस्यनि॥सूवर्तूपवः॥श्रीमानरूफकाङ्कनसन्निहा॥पमपूष्यूवदूरुसःसारसाजासूष्यिन
पङ्क्तिवासविवायिनस्त्र॥यसिवस्तिनःसूवर्तूवनकायर्तूसक्षनेमूनिरावृता॥सम्मुसाकयमातव
ङ्कसाकयिनामरुःपूसनासाकनास्यसाकयासातथावदीत॥पाकंसाकपासानीयर्वदानानूमसनाङ्क
नाग्दवूर्हीजायतेवर्हीःपश्चकजाश्रथपिनाङ्कूनस्वग्रावकोत्यर्हिदवास्मयिसमूद्विता॥जार्यंतवना ४१
स्मेवर्षेउंगमवेदयासगा॥श्रषयथमसाकागमङ्कूनाग्रमनवाङ्कनाश्रसाकासूकानांयूक्ष्मकेवंव्यनः
मानूषीयजा॥वङ्कनावचनंङ्ग्रखाखकपासावचेकुवनाप्रवंमनमसावाङ्कनेवमनमसामूनोप्रत्र
यिहमयिव्यानिःसमनासागसायंवा॥सूमसूकन्यथि सानुधसनीयसिवस्यवा॥वधयिव्यामपाहन

नचद्रुसूर्यीनथानि॥समनासागसायंवःसूमसूकन्यथि सानुधसनीयसिवस्यवा॥वधयिव्यामपाहन
सूर्यीनथानिसं॥नक्षनानिचस्वानिगमदनाखादनचा॥दिशश्चदशनाहोगमकुषानेव्यामा॥सर्वदाःय
पदूश्रहयिव्यातिःवेशक्तिनोघनाःसाकस्सवदवकाङ्कषग्रहनेहूनकासनाता॥पसाकवन्तिहनानि
हूस्कमानूषीयजी॥श्रनमनवसाकामंदकयिनियसाकमं॥श्रनिकामतियाविश्वीमनानोषधने
षष्ठमवाविस्यानिकानाता॥पसिखदःसमनाद्रुनङ्गिना॥कुलासमानयिव्यामासाकेनाथस्यवाग
नाकषीदनुंपतयामिसनंवङ्कानिमिनोयस्यदेवाषकुविस्यमाहाङ्कूनमद्रुसं॥वृकुस्यया
यावदिखाश्रोसाङ्कनयसस्यसं॥सूवर्गूसूपसदृश्यिमकायास्कृदिव॥समसासासमगहेस्यसकस

नृसमाकृता॥सदक्षासा॥सावस्तावत्रयुत॥संस्कृतान्यथानाविस्तकमासस्यंयकानत्रावेहयसंगमात॥
नतोहिचक्रासाजानःपकातारुतमनुतेयत्रापर्नमहिकृत्वाचूर्ण्मपिहिसमया॥यथासावेत्रहिन
गसेसूतपाहानथाविव॥यक्षसनोपतिसवोत्यथयित्वाचतुर्दिशं॥सोनेयसवहूतानिमावना
समनतादिशि॥साहूतपमहंनेयुतसंज्ञतुसतमलिं॥वक्रतोकासमूदितसवदवविचिनिशं॥म ४८
हासाहसकायनदनमदितायक्षसाक्षसा॥त्रस्तावाक्रकुवेरस्ययक्षसनायनिशि॥विकमनवतुदा
क्षयार्थंचयक्षपत्यनिगृक्रका॥अथाविसनिवहूतानिगहागवेवशामनो॥यस्मिन्मदिनोकालतसं
यागृत्यकुमा॥सवंनसूतपाहानयवत्रवमनपीडिता॥अक्षाविंसनिवहूतानिगहाकृक्षाणुशामन

दक्षिणस्मिदिशिहागुहूतसेया॥शुक्लमनुमासवंकसूतपाहानयवत्रवमनपीडिता॥अक्षाविंसनिंव
हूतानिहानिनागगहामूने॥पश्चिमस्मिंदिशिहागहूतस्या॥शूनामःसवंनसूतपाहानयक
वंधनपीडिता॥अक्षाविंशतिनिस्कृतानिहानियसगहामूने॥दिक्षागउकसेवाधिहूतसेया॥शूना
नुमासवंनसूतपाहानयत्रवंधयिडीता॥अथयूतकुवेरस्यसेजयोनसवाहन॥पायमूनेःउनंथे
वयक्षानीवस्थिकादृया॥साकुथासूतपाहानयकवंधनपिडिता॥यूतहूतीयकुसेवनात्रास्थासो
मक्षागक्षा॥पादमूसेतुतसेवयक्षानीवथिकादृया॥त्रवासूतपाहानयवत्रवंधनपिडिता॥यूतहूती
यकुसेवनात्रास्थासोमक्षागक्षा॥पादमूसेतुतसेवयक्षानीवथिकादृया॥साकुथासूतपाहानयवत्रनपी

मक्षमसामरादकस्मर्गुवाहुमकावस॥पादमूलेनुतस्यवपक्षानीषधिकादृश॥सरा कथायूतपक्ष
नपक्षवंधनपक्षिणा॥आगत्यसदकूनानिपवनेहतमदनो॥ब्रषाउकाविनाविश्वासूवविश्वासम्यः
कूरा॥निकरेषूषदनुंसववृहःकिलासिनं॥यषगच्छमगसनंसवैलोनमसादरा॥सरसाथनानूव ४८
लूथमावसवैनरुषथ॥नमसूहनमानन्नतनसंघासमागना॥पवनेषूसमूदेषूससमूवा॥नन्दिपगवना
कषूआवर्लषूकथस्थिता॥उद्यानेषूविमानेषूआवर्लषूवनषूव॥वैद्यस्थानैषदक्षमूलेषूयस्थिता॥न
गसस्यपक्षगारवूनिगमजनपदखूव॥साजकूलेविमानेषूवयस्थिता॥मनुषूसमगनेनथदवक
खूव॥सिमसमूशुक्रगासायांशुन्वागसेषूजांगसजहेहथंवयपक्षासमुद्रिक्षूविदिक्षूव॥यक्षकाडि

सहनानिविक्षपाडनकर्षिता॥मदंगावादिकूलकर्षिर्द्रुसवादिनं॥विनापनववैनूंखवादयकामः
हावसा॥कूलावादिनंविनंगाधवनाद्यमवव॥छंदसामवसूनोहस्तदाऊ॥पक्षापतिःमानसिसाक्षि
क्षस्वकिनवनम्वपूर्तिकावदुनकामशुक्लीचमनिकूलनिकष्टका॥यशामूलूर्यिताम्वदवसूतगुः
मानसिपविकस्यनगाधवानस्साजाकिनवीरु॥नथापवसिक्षनामतुवूलूःसर्यवसःसेलस्ववाक्सिपूतवि
क्षकमिनायतावसाऽरदवकःस्मनावनूवीकूमदिसिमूखा॥पाकसगासुसमूवासमे न्यवसवाहु
नमादवानागास्वर्गधर्वाऽरसूसायक्षसाङ्गसा॥नैनियकस्वऽमादाकथावाऽथकोऽहस॥यवसाकवि
हठनिपदथायक्षसाङ्गसा॥चतुर्दिक्षसमानीयपक्षवैधनपिंडिता॥ब्राह्मसिकाःपूरःकिलसाकः

नाथमथवावा॥नमस्कृत्यसूक्ष्मावैसनमस्कृत्यसूक्ष्मालुमपाङ्गुलिकानमस्यामाद्यमतागनस्कृत्वाभवतिपूर्व
तुस्कृष्टंकृत्वायक्षामहाकर्या॥वक्तुकामहाकर्णावहत्यादेकपादका॥चतुष्पादाहिपादाश्चउद्दंष्ट्राअल्प
मुखा॥वहुकायेकगाधश्चेत्रकंकायाश्चतुःसिराः वाहुनेत्राईकायाश्चत्रकाक्षाचादंष्ट्रादता॥खरशकृत्
स्कृसीर्षाश्चउर्द्धहस्ताअधःशिराः गमकहस्ताः गमकवाहुगमकपादाश्चसाक्षसा॥तामकेशमस्कानदनास्कृताः ४८
मपानय॥तामस्कृतपादाश्चतामनासाअर्थामस्वा॥आदिकहस्तपादाश्चमनुष्यतनूनाहिता॥कृत्वा
कूक्ष्मस्कुगस्तजाविकूनक्षाविगमुकाः॥मकरत्वाउत्पाश्चविसृपा॥सकेशमुखा॥सर्पावकदतास्यप
दृष्ट्वारक्तीमुखा॥स्कूलदशकूस्कर्णस्रस्तकर्णश्चकर्णश्रुकाः॥दिपकर्णादिपवाहुद्विप

नासागपानय॥शुष्ककामादिपकामादिर्घकेशाःस्यलैकत्रा॥पादशाःकृपागीवादुर्गंधाकलशदंता॥क
स्यसपश्चआस्यमूलसंमूगशदंता॥उद्दंष्टनामहाकर्णउद्दंकशमसूताहिता॥स्कूलेशीर्षीधनूगीवाकृ
क्ष्मा॥कूस्कादशादषा॥वहपूवद्धिवषानिमस्मृहिविज्ञात्वा॥दक्षपवनपाषानमऊकूदसमधृति॥स
खरहस्तिमृदङ्गनाकूस्कादुंदुभ्यशा॥पमूत्रनिवसस्थिमेमहाकन्था॥खस्यशाःकाशनीशकपीनाश्च
हस्तिपिङ्गलयोगशो॥सर्वाशामासिकशमश्रुसकशाहितमक्षिका॥हस्तमानाविधवेनिकूनसंपंप्रगृह्यवे॥नी
लदशगनहस्ताऽथमक्षिकशहिता॥अहिखादिनगात्रास्युकृत्वाहस्तेपपूसिनी॥दृष्टाहृदयजंतुनि
रूपनलक्षमानका॥कशाहस्कूपादुस्कूहस्तेनपानिनीवशे॥अस्थिसंकशकायसमशास्यनिहनान्य

हा॥ गृहित्वा मानुषं चर्म सहितेन पयस्विनं॥ विषं नागेन संसृष्टं सिंघनिर्दिग्धदंग॥ नासानीयवेशप्र
विशेषनि॥ कुलाकुलैः वानरिनैकरक्षमानौसीकारयनिवनुर्दिशौ॥ व्यनिसैनिथनत्रनसाऽपिशाम
कारया॥ सवेसमागतासुरविद्यापोतनकर्मिता॥ नमस्कृत्वासुरक्षोत्तमं॥ नम
स्यमाऽकुलाधर्मसाऽनमस्कृत॥ वसनिनासं ग्रामेसाकुलाऽकुलेषुवा॥ यक्षऽजाऽहसाम रान्ध
मान्सासूप्रिसोसिन॥ महाकायामहाहिमामहावसमहाबसा॥ दग्धग्रीवा॥ सहमाक्षमलाग्रसाम
लामूषा॥ महाप्रसिवारेनसस्कृत्वा॥ सहेसवा॥ स्रहिवर्मागृहिता षडंकाहलाचकुर्दृशा॥ दनुकुल
गमस्कृत्वा॥ गृहिनावशेवानिर्मृ॥ उलाहनिदिसः सवान्पूक्त्वासूदासनै॥ वसनमुर्द्धकाः सवद्
धनासयोस्त्रिकोः ग्रहसनमानूद्यसोकनस गृह्यंसुखेनसान॥ ऊर्ध्वमासेत्वसूप्रिसेशुवाक्षा॥ काम

सूपिन॥ सिंघव्याघ्रंत्वमक्षीणाऽत्मासाकुलसूपिननै॥ अक्षाहीपिदृश्यकृत्मासेऽविशासकः॥
सूपेसाकुक्षकपिखैः खनिगृकसनाकुलैः॥ मसकछमसूपेभ्वलपसै॥ काकेकोकिले॥ वासूक्रगृध
सन्यादिनऽनिमिनिमिगिसे॥ मायूसेहंसकापोतैसयैः कलेविक्रमे॥ कविकूकुटसूपनयः
क्षयसानिमानूषान॥ सूपगृपक्षिवशनसकासतिक्रनीवहनाकर्षाविस्मानूषंगाबैगसिसंख
कोकुटैः॥ सरयानस्थिवकादृग्धकविकासस्या॥ विनमाकानपवमाऽनमासावमृत्तिका॥ या
हसनिनिगूसेनपिताकूर्वतियानिनौ॥ मूकविदासनैभासीसकासयंनिऽनौपजौ॥ विविनः
सूपादग्धकयावैनिषानसकनि॥ गृहिनपर्वतेभाऽऽऽसिवकंधसापसै॥ सैन्धवाः सवसकुऽभनि

मूखसादनुनशिवा॥उल्लाटिनाक्षविनखा॥खेददनाथसाश्रमसा॥छिन्नभिन्नशिखिनशिवसीमूषाःसी
छिन्नलम्बादाश्छिन्नसिखाश्वेताक्षसा॥पक्षनखावनाहेडिडोजाहिनिकृत्तीवा॥मालूषानोमसी
रेषूनुक्षादग्धनग्रहा॥सामानरेषूमभेक्षनथवनमूखदूवा॥सवसमागनाकूविद्यापाशकनविना
ननरूपूलषविसननक्षवत्क्षर्म॥नमस्यानाकूसिकसाधर्मिसागेनम्मसकुन॥सूमसागिसि ५०
साजनवकवाजधेववा॥गृटकूटेऊषाधासेहिमवाकूधमादने॥पानुवेविनकूटवनानदेप
वकर्ट्यं॥आयवनस्यमूर्छरा॥मूक्षायेरुगमूगना॥यानतदक्तोधरूपादूषयन्धसमाश्रिता॥वद्
वूरूपवाविम्मसायूक्षनलमानसा॥देवकोटिसहमानिदेवकोटीगनानिच॥देवकंन्यासह

सान्मजरकूसिसंपगृक्षवे॥वेमविनिवसाकूस्यपक्षूदश्वसमागना॥हस्यकोटीसहमेस्वहस्यकोटीस
नेसाथि॥कन्याकूषांमहिवस्यावदासेनखीजति॥सागलःसूपतियचनागसाजानस्थि॥ना
गदानवनकस्यउशनदापनन्दुको॥वक्षनदावजनंनिगरूसिधूस्यसागसा॥सपत्नीपक्षिसाजानः
सागरस्यहस्यनिवा॥नागकोटिसहमानिनागकोटीगनेरूथा॥कन्याकूषांमहसागरसरकूसिसंपगृ
क्षवो॥सविवादावूलेवाथिनक्षकपतिवाति॥सवसूविनयूक्षवूमधस्वरूपेषक॥कापासिहस्तक
क्षूषकासतेषूपतूकं॥सूविसनाचमदषूमस्तेषूवयक्षमधस॥विहंपनन्दुपावासे साहिगाक्षस्यश्र
स्वक्षाधिक्षसस्वश्रवस्तेषूकथितोक्षस्यवेदिमकूक्षादसस्यमस्यवशूसकेषूवदिधिन॥पमर्दन

संकासनिर्दिग्धदग्धस्त्रियग्वपूषश्चयिनथादासकट्वासिका॥गरुत्साश्यिनश्चनिर्निर्यग्यानी
क्षताश्यिनिक्षनत्वद्रसूर्य्यस्वग्रहा॥पित्तनिदासनाःसत्यषूर्य्यकेसंवीजंमाषधंपानक्षुजनं॥कुस
नमानुषिसश्लीमूत्वानिन्दिकासनिव॥यकृच्चिद्दुकुलौकेकेसा॥कसहविगदःदग्धनथदुनः
क्षिन्नतस्वंदूतगंस्मरनं॥उंगुदुनिगुक्तियंयस्यनिन्दिहनिव॥उलासनिचसत्वानांविष ५३
क्षनिन्दिहनिव॥दर्शयिनिपायकास्यप्रानपसूकानपिठ्यनिव॥द्वासस्लोछकटंकुलाप
यकामनिगासनिव॥मिनक्षनिससूयास्यदृग्धनस्लिहनिव॥विविनकंचकासूयस्यदृग्धः
नकामसूयिन॥चन्दसूयनदृग्धनेसूर्यनक्षनसूयिने॥वानाकासनिसूयनदृग्धनुवायूयी

उकाउल्काकसूयसदृसाःगंगमस्लस्लहेत्वा॥विकमनस्यदृग्धनेवक्षचेष्टास्यषूवा॥कू
मासस्पनगसंगासकलास्यसासदाविकानिदसनिसास्यषूपथषूवा॥गृहानीनासासना
क्षद्रासेमूक्तिकासा॥गृहिलाक्रिविनंकायंकेकूपथनांनसंवा॥विविनाविविविनिसो
गमस्त्रिचिनोदर्शयिनिस्थाश्चिचेकायसंस्लिष्टा॥विषसिनकदसनिसर्वसागषूलक्षनं॥यावः
नीयकूनिसाकसवादस्तेनिनेन्द्रयथाःसवेसमावगनाकूपिविद्यापालनकषिका॥नकूप
स्पषवीलनमकूपूलषानम॥नमस्वामाकसिकसाधमस्वाऊनमकूका॥वेगवनोमहाराः
ऊउस्लिऊथदूनाकूसि॥वकोकविनवलनैथिकाक्षनसनिहं॥लोकयस्याकूकसनंसकि

कस्यमहामूनेःवसुधासिरहासानियक्षनीमंनपकासनाःसिनाथकुरिदिग्राःगंधीड्यनिन
दूरवानाःकषांदकुप्रलयाभिसोकनाथस्यसमूर्खाःस्यात्यक्षदंःखगाःखगाःखगाःगरुविं
वक्षनेवकवकलोकनेवंदवपरेहिमयवनेःखलोगाःकुंदिकसाग्राःब्रकाशिवर्जिवनिः
गरुवनिःसरङ्गवत्रिःचिनवनिःचिनकानिःस्यस्यकुसमसवसखीनाकरुलदिसिस्याहाःवक्रवध्यध
सकसोकपालामरुस्यसःयक्षसेनापनयःसंरहासिनिवसमूनिकाःकंदपूर्वीकगंधकपनिगंधकु
सामहंनिःकंजनकंजसाकर्वीत्रेस्यनवसेनयनिरुहाःसवसागन्धस्यस्यकुसमसवसिखीनाश्वस
रुयपदकावस्यगंधःस्याहाःनमरुपूस्पवसिसनमरुपूस्पाकुनिःनेमस्यामारुतिकसाधन

लाजानमाम्रुनिःवरुसाकुरुसमहासागत्कनाकुरितस्रिनाःरुसनसिनिवादलकलविकस्तुमस
मातंकाकिसनिर्यषिमयदन्दुहिगनिनाःवसुधासिरहमानिगवर्वीसाक्षसामूनाःनिरुनाःपूव
दिग्हागंपीड्यनिनदंदुवानाःरुषादंशुप्रलयाभिसोकनाथस्यसंमूर्खाःस्यात्यक्षदंःवसनिःश्वा
सात्रिःवूवपध्वंसनिःजंभनिपभ्रुनिःरुनिःपभ्रुनिःविषमनिःकिंपूरुषःसकसेःसालथः
सालवनिःकुलधसेसूलधलिनिःगुर्वंवसलाःयाषवनिःसालाःगमनिःस्यस्यकुसमसवसिखी
नाश्वसवरुयायद्रवरुणापूवर्वीदिगिस्याहाःवक्राकावापधनुवसोकपालामरुस्याःयक्षसे
नायरुयाःसवरुहासित्रिवसपूनिकाःकंदपूर्वीकगंधकपनिगंधकुसमसारुत्रिवीयनेगसा

नमो मेघ्यनर्वसेनवानिकृतासवशोगाश्वस्त्यक्षुमनसर्वसत्वानाञ्चसर्वहृयपदवेश्यस्त्रा
क्षा॥नमस्फुपूत्खविसनमस्फुपूत्षाठम॥नमस्त्रीमा॥सितकसावमेसाक्षानमसस्फुत॥सा॥
विसूडकस्माधिषाकृसितकसकोहिना॥सवस्फुःसवदमिवसवबादिपमर्दन॥सर्वसितयकैला
वसवसाकविनायक॥वसुःधमिसहमानिकूस्त्राक्षु॥नयनपूतना॥निजयादस्मिनंदयीउय
निमदूहवान॥नमोदगुंपत्नेष्यमिसाकनाथस्वसमूर्वं॥स्याचथदं॥धर्मिवसासवतिकाकिका
वति॥कैकसिकिसिकिसिकिसिवसिवसनिवहुनि॥स्फुमिधासनिस्फनवनिस्काविस्वस्ने
मालाग्रिस्यस्फुमनसर्वसत्वानासवस्यीपदवेश्य॥दक्षिनस्त्रीदिसित्यासा॥ब्रह्मापथस

साकपासानस्फुसस्त्रा॥यक्षसेनापत्यःसवेहासिनिवसस्त्रीका॥स्फुदंपूर्वीवगाधस्फुपनिमस्फुकुमसा
स्फुत्रिं॥वीर्यनिकजसानमोमैत्यसावसेनव॥निहसासवशोगाश्वस्त्यक्षुमनसर्वसत्वानावसवस्फु
पदुवेस्वस्त्यासा॥नमस्फुपूत्खविसनमस्फुपूत्षाठमो॥नमस्त्रीमा॥सितकसाधर्मसाजनमाक्षुत
पूर्वदिसाधिविसूयाक्षानकासाजाग्रहनाकसित्यूक्षिन॥सकासाधमसकासिंहमसकासनमस्फुस्फु
मसकावाद्रिमसकानुलमसकासंगममनदसक॥वसुधथिस्फुमानिनासाशोपनिगुस्फुका॥निजयाय
विदमासंपीउयनिगदूहवान॥नमोदगुंपत्नेष्यमिसाकनाथस्वमूर्वं॥स्याचथदं॥धर्मिवसासवस्फु
वतिवासिनिविमस्फु॥विवसिसागसेखसिकथिसेचसुसिकिसिनिविसाजक॥विमसिनि॥वनव

त्रिस्वरसेन॥ सूक्ष्मकुसुमसदृशवासरत्नसर्वसन्तानावसवीर्यायद्रवत्वात्परिमाणादिसिद्धत्वात्॥वक्ष्यमाणयथासङ्ख्यसामर्थ्यस्य॥यक्षसनापनयस्तत्वसिद्धिर्विशेषपूर्विका॥ इदंपूर्वंचगंधस्यनिर्मूलकुसुमसादृश्यात्॥वीर्यनकुलकुशेशयसदृशनिर्देशवसन्तसर्वसन्तानांवसवीर्यायद्रवत्वात्सिद्धत्वात्॥नमस्कृत्यसूक्ष्मविलसनमस्कृत्यसूक्ष्मसौरभिकसौधसाजनमस्कृत॥ सर्वदेवपूजास्नानकुशविलेपनमस्कृत्यसूक्ष्मसौरभिकसौधसाजनानन्दा॥सर्वसाकल्यविकल्पक॥यक्षसनाप्रमाणेवदिग्विदिक्षुयवहिना॥ज्ञानात्

रहस्यहेतुकस्यसाकल्पनिर्देशनागता॥ इदंपूर्वंचगंधस्यनिर्मूलकुसुमसादृश्यात्॥वक्ष्यमाणयथासङ्ख्यसामर्थ्यस्य॥यक्षसनापनयस्तत्वसिद्धिर्विशेषपूर्विका॥ इदंपूर्वंचगंधस्यनिर्मूलकुसुमसादृश्यात्॥वीर्यनकुलकुशेशयसदृशनिर्देशवसन्तसर्वसन्तानांवसवीर्यायद्रवत्वात्सिद्धत्वात्॥नमस्कृत्यसूक्ष्मविलसनमस्कृत्यसूक्ष्मसौरभिकसौधसाजनमस्कृत॥ सर्वदेवपूजास्नानकुशविलेपनमस्कृत्यसूक्ष्मसौरभिकसौधसाजनानन्दा॥सर्वसाकल्यविकल्पक॥यक्षसनाप्रमाणेवदिग्विदिक्षुयवहिना॥ज्ञानात्

स्यायसमासकस्यसवक्षकस्यसठनयवक्षनिकायाःपजायाःसदवमानूसूतायावृक्षिरगवनासीकउस्य
यनानत्वथास्याहियविकिसकःपसमावार्यकूठासाहिगहनेसूसिक्षिकानेकसत्वस्याथयनेकऊनव
दस्याथयसाकउस्यचनानःसकस्यकनाप्यस्यादिसिवृक्षहगवनाविरुसनिरतमनूष्यानिरुपयितव्या
मन्यनायवहंयनवेणसीमहानगसिनेनापसंकमर्थःप्रवंमयावैस्यामहानगस्थीमहाजनकाय
स्याथयकूनाहविर्थंसिवृक्षकायेकःअथसहस्रानानपूर्वीद्धकासत्तमयनहिनिवास्यपानविवसः
मादायःसर्वंनयादसहिहिंक्षठानेःसार्धंगृधकूटास्यवनाद्रवत्रिशृंःअथवक्षासहापनिपक्षमानानी
दिथानिरुनसनान्यदायहगवंनोदक्षिनेपनामिनवानःउपनामनहगवनमवविरुयमानःस्निन

स्वलासीमहासाज्ञानःदिवानिपक्षमाहानिरुनहनान्यादायहगवनाःपृथक्रउपनामिनवनःउपनामहगाव
नमवविरुयमानहिनाहनःनरुद्धसापिदवपूनरथविंगतिहिस्वमनहायक्षसनापनयाहानिं
जास्वमहायक्षनमहासीनिवसपूनिकासपसिवासाभवकानीपरुकंदिव्यरुनमूपनामिनवनिवी
रुयनिवस्निनाःप्रवंसूपयभासासत्कासागयापाहगवानसहिक्षसेधारूधकूनस्वर्तादवनियंय
नवेणसीमहानगसीनेनापसंकानःअदाक्षूखसूपनवेणसकासिरुवयाहगावनंदूसनप्रवागरुवं
यास्यादिकंदसनियंभनदियंसानमात्तनंसंदानमासनंपरक्रमंगमथपाकमुफदियंनागमिव
सूदानंप्रदमिवाकंविपसन्नमनानिसंहानिंगहिमहापूसूखलक्षनेःसमसंकुंभमनगनिहिस्यन्

यक्ष्मनेा॥सेकसूत्रमिदंविधिर्नंगथागतस्त्रीसंगासत्ताजंजवसूत्रंविदंसूर्यीवादिवापसूतस्त्रमिदंशास्त्राकेवांधकास्
तनिष्ठ्रयीगिसिसिषसगत॥पठास्तनिवमहानधिस्कधा॥नस्तानिवकस्वसुभसं॥यवमवहेगावाकास्य
नयकनिधिसंचन॥सहदस्नाद्ववद्वेभसकासिस्कुवयाहगावुगानिकवेगोसिपसादयामासु॥स्व
पस्तनविताघनमाशेनहगावों वेसासिनहा॥नगसिंपधिस्तनिमार्गिहमवयनिस्मासिकस्यनिस्मपू
व्याकावकिसूंऋकूवनिस्म॥उस्किनविधिनपद्दानपस्तकुनस्वपनाकानानाभनिवूधिदंवकुस्व
यनहगावंकुनापसंकामनिस्म॥उपकसंमहगवनःपानुयामिसस्तानिपवनिस्म॥अथहगावासह
मासवकसूंविलविसिधिनसेपमधिव्याहकूस्मासेनपूर्ववसिनसक्षालभपविनननसूनदि

वाकवकिलानाभिवेकपहेनप्रहुनयसनवकुवसिमसनसकमनिमलकसेनत्रषीसिकुविनींसीपसिमा
स्कीस्कायसमनसासंनिस्म॥मासेमासेमार्वत्रषारमहस्यागेायूष्माकंमेवानकस्यामूघादाया॥अनूरुसंस्थान
मस्तिंवृक्षास्मिसवसत्वाना॥ऋद्धिनायसत्वया॥अथहगावानवेशासिमहानगसीपविघ्नमथमयाकु
न्द्रकिलमवथस्यचतुर्दिशमवसक्कसूवसूविधूवाकूंपसायाकलासंनंविवसिनावावा॥युकविस्यम्वमे
कालेयस्मिमसनयसर्षपरुसमातुंनथागतश्चनिवसमतुंपूजयिष्यतिा॥कूमाऋमहासाकूंपईनिविस्यासा
स्कीसवगहयभावनिर्यंधमपयार्यंगजयसिकत्रायस्यानांनथागतानामहतांसत्यवृक्षवृहानांवूधमूढाहिकु
रुक्षन्धूपासकोपासीकाऽगृहिष्यतिअसयिनिवाचयिष्यतिदसयिष्यतिपर्यवोप्स्यतिा॥नषासवऋ

निरुद्यायदवायस्तर्मपायासाःकलिकलहवंबनविग्रहविवादाअनर्थेभूत्यपायकाअरकृगसाधमानक
निष्यनि॥अजयाम्बरविष्यतिसर्वविरुद्धकर्त्या॥अवंमूकवक्त्रासक्तायनिरुगवक्त्रमनुवाचगाकुत्रमासाह
दतरुगवनमारुहासारुपमद्रर्दिनामसरुविक्षसाश्लोत्तवगारुयमावनियोधमपर्यायंगांगसिकतापरवानानथ
गनानामसरुतासंम्यक्कवृहीनांवूधमूद्धा॥अवमूतेरुगवांवक्त्रानंसक्तायनिमनुदवुवता॥कनकिंचवक्त्रनगून
साम्बमननसिकूरुरुविष्यरुता॥अवंरुदंतनिवक्त्रासक्तपनिरुगवक्त्र॥प्रत्यंगमषीतरुगवांकत्येनदवता॥स्याद्यथदं॥अवरो
चमवेसामन्वरे॥पकृनिवशृंगकृनिनिशाषेसमनमूखस्किवेलावरेविद्यूरुगदयंत्रनेपासंगमसासंगविसा
संगवनिवरेमरुविरासत्याहा॥नत्रदंमूस्यतकायगनानूस्तनिसमथविपश्चनेत्य॥समाभ्य॥वाक्यासरा

हुंपाहा॥वचासिसत्यस्त्रंहानानिन्वत्वासिसत्यंयुपस्थानानि॥चत्वासिक्षानानिन्वत्वार्यसत्यानिपस्कंदियानिप
स्कंवसानि॥षडनूस्तरत्यासमस्कंवाक्यंगमनि॥अरार्यक्षुज्ञानार्गा॥नवानूपूर्वविरासत्तमायतत्यादशनथा
गतवासानि॥यकाद्रुगविमूक्तायतनानिः हादसांगयनियतमूत्यादा॥ठीदसाकासंभमवकंपोउभकासंस्र
नापानानूस्तनि॥अरथादशभवेनिकावूधडर्मा॥हाकस्वासिंहादक्षसानि॥ऊर्यसावक्त्रासक्तासाहसमपमदनिनामहा
विद्यासाश्लोसर्वगरुपमावनियंसतंगोक्षसिकतापरवानात्रथगतानामदतीतस्यस्त्रंवृहीनांवूधमूदा॥वृहनि
हासंवनिहाचंःसंघनिलथंवक्त्रनिहासंःकूंदनिहासंःलोकपालनिहासंःऽऽत्यसिनिहासंःसत्यनिहासंःमाग
निहासंःयतिनेतमूत्यादनिहासःचन्दनिहासंःसूर्यनिहासंःग्रहनक्षत्रनिहासंःस्याद्यथदं॥अमनेकसिनेविसिनि

गङ्गासागरसङ्गमे हरिहरक्षेत्रे सरोमानसे
धेनातीरतपोवने तटवने कावेरिकानर्मदे ।
चान्द्रादित्यजलेषु पुष्करमुखे कौशिक्यरण्ये
तीर्थे गोदशताह्वये हिमवति श्रीकेदारे वसन् ॥
यत्पापं मनसि स्थितं पुनरिह क्षेत्रेषु वाचा कृतं
तत्सर्वं तनुते वपुर्जनिमतां जन्मान्तरे वा पुनः ।
तत्सर्वं विनिहन्ति पुण्यमतुलं तीर्थेषु गत्वा नरो
यो वा पुण्यमिदं पठेत्तदनिशं भक्त्या शिवस्याग्रतः ॥
इति श्रीमहादेवस्तोत्रं समाप्तम् ॥

॥ अथ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २ ॥
शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४ ॥
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ६ ॥
॥ इति श्रीशिवपञ्चाक्षरस्तोत्रं समाप्तम् ॥

॥ अथ श्रीशिवमानसपूजास्तोत्रम् ॥

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयो दधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जिरेण सहितं हिङ्गुजीरकान्वितं
ताम्बूलं च गृहाण शम्भो करुणासिन्धो जगत्पते ॥ २ ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४ ॥
कर करोतु बाहू करोतु

यथादक्षिणेदृथिवीनिधिताऊर्दिनंवायूपक्वंपानेथामयाऽयुसस्तिसंपश्यश्रायंमागीस्ववत्स्यदक्षिनि॥ऊ
र्ध्वनानंवत्सघलतूमतनत्सथनऊंहामुत्स्वक्षि॥यज्ञांगमाआतनुथेवस्रावसाऊसवीसखिनोहवंतुऊमतं
कायापद्वानकेमनस्यकृत्वानेहयंकऊसवाप्रवति॥ऊर्दंपलिनवत्सघत्तमतनत्सथनऊंहामुत्स्वक्षी
ऊर्वियंथिवायूवऽमधिनकाअर्द्धगतानेवऽपेनिसंस्वानथेवत्संयाजनविप्रयूकाऽराऽऽनंनयानिधिवू ८१
द्धयूता॥ऊर्दंपनिनंवत्संघरनमतनत्सथनऊंहामुत्स्वक्षि॥यज्ञंगमाआतनुथेवस्रावसाऊसवी
सखासूखिनोहवंतुऊमत्कारमग्नंनलदवपूंवूंवनत्सथनऊंहामुत्स्वक्षि॥यज्ञंगमाआतनुथेव॥
स्रावसाऊसवीसखासूखिनोहवंतुऊमतंविसाग्रनलदवपूंधमनत्सथनऊंहामुत्स्वक्षि॥यज्ञंगमाआ

तनुथेवस्रावसाऊसवीसखासूखिनोहवंतुऊमतंविसाग्रनलदवपूंधमनत्सथनऊंहामुत्स्वक्षि॥यज्ञा
हूतानिसत्तागतानिक्षितानिहूमावथवातवीक्षकूर्वंतुमनीषातंपजासूद्विवावचोगवचसंतुधनं॥य
त्सवस्थनगिनाऊंतोसि॥सवसत्यवादिसिपतत्यनाक्षि॥तनेवत्सथनऊंहामुत्स्वक्षि॥मूत्यंतुसवमक्ष
रंयत्स्वाद्धा॥ह्यायथर्दं॥भिरेधिभिरवसनिधोषवसेसावसावेवाऽमुतेपेहपनपाऽमनसेध
रासंघषासावेवाऽस्यूतवसवंतुसपाऽहासालऽमसूर्यवत्सःसूर्यनिर्घोषस्याद्धा॥ऊंदसाक्रमाम
द्धासाहमपमदनिनानविर्धासाहीस्तवगहपमावनीयंसूतंगंऽसिकपर्दीनतगत्रानीनदनासंभ्य
र्कंवहंतोवृषदा॥वृषपदा॥धर्मपेदा॥संघपदा॥वऽक्षपदा॥ऊंदपदा॥शकपासपदा॥ऊंकत्सयदा॥अपर्क

पदा॥ऋक्षिपदा॥नक्षर्षिपदा॥पर्यीक्षियदा॥के तुपदा॥यदसपदा॥अरिहंतवृद्धा॥प्रथकवृद्धेभ्यस्यस्तिनाम
ओवकेलधिहिनाद्वाकलेपसंस्तिना॥इन्द्रेनसंपूजिताश्रीकपालेनमस्कृता॥इन्द्रचेनसंपूजिता॥सर्वि
सर्वदेवनिकायामवावेलहिनेद्रिनाश्रिमेनेद्रियसंस्तिनाऽऋषिहिचलेकनावक्काहिसहिकेनादेवना
हिस्थितिनाद्रास्तकसंवर्तिता॥चक्रवर्तिश्रीकनमस्वसंसर्ववृद्धानीनियीनंप्रथकवृद्धानी॥नियीनंश्र ३२
वकाख्या॥सात्रयीयामवासलमी॥ऽराकातीवाधियक्षानी॥धर्मीमंपवाहनसंक्रेशनी॥मूखातनंमनुस्या
नी॥संदर्शनमार्यनागस्य॥विवरणंमक्षत्रासाक्षी॥ऽदनस्कायदृष्टीनीपयातनेमानपर्वतस्यऽभवनं
संसारसमुन्दस्याऽचालनंसर्वससारस्यापनिताना॥स्कृपवीताना॥ऽदनिमासयातस्यऽकातनीमासय

र्षदा॥ऽगीलनिमाऽवक्तिमस्यऽर्कीसनिर्कृसासंगमनस्यपवेशनिनीवानगतनिष्क्रामतासंसारगृहा
दिनिमस्याश्चयदा॥स्वप्नस्वप्नेयषऽषाधनोसाधियहेद्राविपूलपरुद्रासंकखनिविकषीनिश्रीक
र्षीतविषागवनिा॥गुरुसाधनोवसूनवनिावासवविरुधतोविषस्रमापतुपनिपूर्यागहोस्यस्यस्कुन
मस्ववसत्वानांऽकसर्वहेयापदुवधायासंस्थःस्मृता॥ऽन्यसामकावक्कामकाकुनपनर्दनिनामविश्वासाश्रिस
वकारूपभावनिर्यसूतेगंगमसिकतापक्षागतथागतानामकृतासंस्कृवृद्धानीवृद्धमुद्रा॥ययामूदयामूदी
तासदेवमानुषासूरसाक्षेनूरुसंनिर्वाणपूर्वंपत्रिऽऽयस्यवाथवगंगमसिकतापुरुषागा॥संम्यक्संवू
ढेपरथकवृद्धेभ्यवक्रेस्वपूर्वमस्तिंवृद्धेपरथेकवृद्धाः॥ऽकामानापिरुगूरुसूरुनियादुक्षिनियाम्यू

पाशिनाब्रह्मचर्य्यमूर्ध्वरेतसंरक्षितुंदानंदमंकूपायासमितापत्तिपूर्वकाःसाधिकाबाधिनागीसाधिकाया
धिकायाकाःसर्वरूपायाशीलामाचाऽरथवक्रोत्तदापतिवक्रवेदवानामिद्रचत्वासोमहासाज्ञान॥यक
वाहोकमभूदावनुर्दिसमूदावर्यंपदास्याम॥सूक्ष्मशासहमपमर्दनी॥तस्किसवरूपानिमूदयामूद्रि
नायया॥यमनव्याःयुदूक्षास्वपत्तमाभमनमासने॥मयादशुंप्रलाक्षमिविर्द्धीवृक्षाकालनिमिषा॥शकुन ८३
क्षतिमवूछीसाकपालेस्वमूद्रिता॥स्याद्यथदंकतिरूपाचदूदूदराजामदर्शिकमन्दुसालाशूपाफलेस
मानिनिरूलिनिरूसिमहूचिमहूसूरूमिहूसमा॥कंकंकंदकंहहा॥सूदनिवलोमावतिःकक्षिनेचवनकि
चक्षुतीपरसंचचलाचलेस्याहा॥ऽस्माखलूपूनमहासाहमपमर्दनीविर्द्धीराहांहाव्यमानायोंमयं

निस्तारूमनहासारूमनसाकंमानुषंकिकासनकंपतदिक्षूचदिक्षूहूमाजनेपक्षसाकंसेनिन्नादःपक्
षाःकर्षंचाघाषयनिसमा॥ऽरहादुःखंनहाकंथंनक्षहूतमानावयंविनक्षहूतसंयानावशन्नीनाधसे
र्वधा॥ऽरवश्रयानिरूतानांसंवधामयसम्वरामनेचरूमानिषीदनिसंपश्चनिदूाखिताःऽरथवरूगावा
स्कांरूमिवजनयीमहिनिमिनीनानचवचनुदिगंपयसायनि॥ऽरथचेत्वासनहोराजानम्यक्रुदिक्षुम
हानमनिनासस्कंधमहिनिमिनीनवरा॥स्वाकाक्षायसिभवनि॥ऽरथवक्रोत्तहायनिसयानम्यनाका
समहिनिमिनीनानेयिसकासमानैवेहायसंपनिभवनि॥ऽरथमकादवानामिदाऽस्तिनस
क्किकूनानमस्वभपत्रिदशूचहिनिमायपवर्षिणि॥ऽस्वसमयनेसमनःसहायांसाकंमनोपक

यक्षगन्धर्वनागनिस्त्रिंशनिधाननिधिविद्याधरमहोरगवज्रपादयक्षश्रीसर्वा
निधयोऽनुचरन्तिसर्वर्द्धिमान्कुबेरोमणिभद्रोमाणिभद्रोऽथवैश्रवणोनरदत्तो
मुक्तकानमेयास्तूचनिस्मासिक्षाग्रहणकेकालयामासायाग्निमाहयाहनांयाग्निवृद्धाहनम्याः
गत्रिःअहनयातकेत्यापितंपहेदिवयागनिःसंवृहद्वृद्धिस्यसाहिनोस्यादकस्यच॥ताःनिधिनिध ५४
यनयनिमूदाक्षिपमहिसकश्वास्यस्तनूत्रःअकस्यवत्सम्॥संस्तुक्यक्षसाग्रगचित्तमहद्वृहती
नक्षत्रमहनपनर्दनंसनंजद्विदंगिनरोषिणोविद्यासंगमनिकन्यवहेमन्तेकुयावर्ष्यं॥नवत्सम्यनथैसा
स्योमहानागायांसवैश्रनिहयायदवोपस्तम्पियायासा॥पनिपमहःयक्षसाक्षसमनूक्षमनूक्षा॥स्तुकस्म

कंणावत्समनिकानाः॥वैश्रमस्कान्तिकुवयकृत्तवैवत्सागद्यावित्यानिमूनाःसवमूषसमाधिना।वृद्ध
श्रवयपत्सादनस्तमत्यागनोवहवु॥वमश्रवयपत्सादनस्तमत्यागनावेहवु॥सेधश्रवयपत्सादनस्त
मत्यागनावहवु॥सनतस्तमिनंसस्तनयपूजाहिस्नानकास्तवेनविहस्तनाहंसशुकठमसिकाकाकिस्तम
यूलचकवाककूनालजीवंजिवकयक्षिगनानिमधूवनिकूजनित्स॥विगतकायधिशःसाप्तलक्ष्वं
किनसा॥श्रयष्टिनानिवत्सर्मृगाभुनिवनित्स॥हेलीस्तवंस्तदंगयनवदीत्यवनवस्यथाल्लनस्तपी
नत्रवंयवादनित्स॥दाष्टिन्वविद्यासस्कन्धेत्यास्तकूपक्षकापिंजेदूग्ववत्सासनमासनिस्कवंधक
वक्षानानागश्चन्युनूक्तनित्सम॥हवानागयक्षठनसहमस्वहीहीकास्यनूकू॥श्रनक्षत्रियूर्षा॥श्र

पृथ

रिपदर्धंश्रमानूषाम्यगन्धसाकंपादहृतान्॥अथवलाशमहासाजानपाकृत्यारुगवंनदवाचन॥ऽऽमरुदत
रुगवमहासारुमपर्नदनिर्यंसूतंसवगहृयमाचनियंवूर्हिमूढावमपयायंप॥कश्चिद्विक्षायदंपचिन्ग॥
हान॥कावायभसिऽमृद्भभलयित्वावचयित्वापर्यवाप्यसिंचित्वाग्रहृयित्वाभासयित्वाभिनस्यसंक
रिहृयापदयापस्तर्मपायासावेसकसिकसहविगहरुनुनवधनविवादयाक्षेष्ठुन्चपायकाकूससादृऽग
खावर्मनाभिकमित्यतिश्रेजयाग्रहविधत्रिस्तर्वविद्वंकेरुय॥तेनसाकूत्यसीमावधयित्वुकाभनसूत्रा
हृननिमुक्तुकुतेनपक्रमिषयसिवर्गितेनस्वीमानर्षिशिक्षायदयसिग्रहीतेनस्वीस्वसमचिलेने
सहस्रिंतेनवक्राहसनयूकेनगमनगसनिगमजनपदसाकृसाजस्कानविहासदवकूलेनतमसाहभकुलहसिसासमगयोयशुपासा॥
श्रयगतंकासा॥कृत्वाखावदिसवदसाग्निपहसापूव्यावकिनाभिसंताकृत्वाहासभसहभहनानाना

गधपद्मपिनींकृत्वास्तदीयैर्गानिसर्षपानक्षयित्वासर्वंचतुर्दिशंपक्षकव्यानि॥अस्तोचपक्षकव्यानि॥नाना
लग्नानिवस्त्रानिहासेवनीयानितिर्यस्यानिगतानिनिष्क्रान्त्यपनं॥पवनायिनव्यानि॥विद्यावावलंयिन
व्यासिंमित्वाग्रहयित्वाचहमूलाषपूजनियाग्नानस्यपूर्णवृक्षपतिविम्बंवावृक्षगतीचंवामनरूपनद्
रूपिणश्रवणपवनपतिविम्बम्वाचतुस्तासागरपतिविम्बम्वाचतुस्तासमुद्राकूलोल्ला ७८
पयितव्या॥नानापुष्पैर्नानाधूपैर्नानागन्धैवंस्तकवतुस्तासागस्तुम्बलयक्षसेनापतयं॥यक्षेम
द्रानम्नाहासिनिनांचनात्रानांनयानाचर्शनांपूजाकरव्या॥तेबीवसेनेत्ययोभियतेनचत्यत्तस्तुम
मस्तवीस्त्रानाकृमश्चतुस्तवीस्त्रानां॥सर्वव्याधिस्या॥स्नानस्त्रानहेवंस्तनपनानयनश्च॥यंविद्याश्रा

वर्तयितव्याविवृहंवाल्मोस्तवृक्षपालेवदिशांजनानिसमानीयचत्वासिसूत्रनायवेदर्भानिनिसित
श्रेकामूनिनांराजनालमं॥गृहितंपानिनाग्रस्तंहेषस्तमस्तापनं॥ब्रह्मनस्त्यवाक्यनस्मरतेरुवतुजोष
धं॥हासिसिचनथादविगृह्यपथत्रथाशुहं॥ग्रस्तंकुदलवनीदिर्यंहेषस्तमस्तापनं॥ब्रह्मनस्त्यवाक्यन
स्मरतुस्त्यचूजापहंसवामपहंचापिरुवत्वमस्तागवधंविषविवृहंतेजनंगापनं॥ब्रह्मनमस्त्यवाक्य
नस्मरतुस्त्यचूजापहंसर्वामपहंचापिरुवत्वमस्तागवधंविषविवृहंतेजनंसिंघिनंभवसेनचाविस्तरुस्तः
स्यवाक्यनकंकृंहदत्तनाशिना॥कनकक्षयस्यस्नानेनमस्त्रावेकास्यपस्यच॥ग्रस्तंसिंहस्यवीर्यनरुवत्वं

पितकास्यलिमावयितुकामनतस्यानेनसूचितुनहृदयीअसननिषसूनस्यंविधाउद्राहर्लक्षा।त्र
जसासर्ववृक्षानोपस्थकजिनतजसा॥अर्हतीवेववियनतसर्वेषामतधाविभो॥पस्यायाभस्तिपूतस्यमो
क्षस्यायनस्यवसग्रहिया॥चक्षूषोवानिचूर्हत्यकाश्यपस्यधेगुरोःकोसिन्यपूर्वपाक्षावाश्रानेद्रः
स्यछेनस्वा॥सेख्यावेवक्षकस्येवत्रेक्ष्यर्यनसतकता॥विषयेसाकपालानांमहेभ्यवतेनय॥सनायहि ८८
नांसायजहावीख्यावसग्रहिया॥वीयन्तजसाकषीविषमस्तीविषंसद्रा॥अतमतन्मयदाहनिनिविषाविष
दूखनास्यायथर्दाहलिकेतिनिःनकिवेःहिसाअमतेःअनुलेयनुलेकढकेकयूवोहसहसाखसखस
खवहाखवगजामसूगहस्ताहा॥मूमूकेस्याहा।हितेस्याहा।निहितेस्याहाहताग्रकितासाम्यवेसयाः

ष्टिवीस्फिताःसर्वंवृद्धंधर्मकस्त्रीजयतुमानदाःस्वाहासदंःअमुकंश्रीपूषवहरुसेनिवालिनिस्वाध
साधनिरुपसाकित्रवधवसनिगुह्यकावर्णःमेनमगुप्तकमनिजमुकनिस्वाहाःपजमुकनिस्वाहाःवसव
ऊनिस्वाहाःजयस्वाहाःविजयस्वाहाःजयविजेयस्वाहाःजितावत्यधिकासर्वसत्ववशाकरीत्रीत्रीश्रीयस
लासर्वेष्टंमानाधिश्रीवशकरःअमुकस्यराजोश्रवसाकित्रस्यसोश्रमिताहरुनेमीसहनाचिमस्ववशस्यवा
नामगृह्णिवस्यवदावरुयंहाभिनच्छिनत्वांयत्रवश्रीवशमाननायक्षाणीनांनामानिकिर्ल्यश्रनुगस्त
थांनगस्यश्रभिनविषंनसर्वकमनकायनकृतसंपचित्रस्यवेदसोश्रायातनडयपक्षिनाडस्फिक
गाम्भवधकयसंमूखीश्रनूसमसहनाश्रवसाकिनस्यसंनरवलुखनीपयनेयूगाम्भा॥सम्विडम्हिनं

सस्तनथगामिकास्त्रिंगृहीतम्भुनाहिनदन्तिस्तनोकामिनियगृहीतम्भुपसूकसंयसादतिसेवनी
पगृह्णुजिह्वादनेखादनीयूतनापगृहितम्भुकेसत्रस्तनतथमातिनदागृहितम्भुविचित्रलूप
मादिगनागकुनीपगृहितस्यगाधपूत्रिपवायानाकस्थपानिगृहितस्यकथासपतिचूर्णनासूखमन
स्त्रीगृहितम्भुठेर्यंतुवविचित्रत्रीश्रीरम्वाग्रगृहीतस्यदिक्षाभस्यजायनाःतुचूर्णसमाख्यायथा
नासतिदासकानामश्रकागवयचूपनस्गताजान्यमयथा॥स्कन्दकूमालचूपनश्रपसमानाश्रुगस्त
वत्रःनूखिकाक्राकचूपनकामिनीःचवनिश्चनचूपजगपूतनाःमाहनदाविडोसेनसकुनीपक्षिसपोनी
कस्थपानिकाकूढनजीसूकनमूखनस्त्रीका॥श्रासवाजेतुचूपनश्चनाक्षासतिदासकानःचनाःश्रुक

हृत्वाद्यासाद्यालकानींद्रयकलाश्चनाः समानयिष्यामिसूनयाशनकपिलावदनानामगवांयक्षसेना
पतिमहानाटस्यवेषंचमुद्राकृत्वादूतेनप्रेषयतांऽगस्कृत्समानेहिवैनाट्यशुद्धसगद्गानाकेनतस्कु
मानिताःपरवधनपितिद्यातत्रावधीनद्गावक्त्रालोकनार्थंकृताश्चसिम्नानिताःनिहतानिवीजनाशतिपादि
नीःकेषाद्रगुप्रहस्ताभिलाकनाथस्यसंमूर्धीयस्यानजायतेपूर्णाजात्रावायस्यगृहक्त्राःसिक्षासर्वमंचसनम १०
वसीसवनुदसिंचेत्यंतंपूजयित्वातुसहाताभूविहृपिताःसर्वपातिफलसनिगवपूर्व्यसमाकुलाःपरवशा
नसूनुनगद्धिनकालयकृतोऽरहातहिंतेकासेनहिकृत्वातुसर्वपानावक्त्रनिमित्तमिलाहृवक्त्रनाचपक
स्यितायावद्दादशवर्षानाकूमालानीहिनंकतियहृनामनिकमहिंपीसूनंवक्त्रानिर्मितांसफलास्यहृदमूर्धास्य

पिहृवस्तमंहृजिवयानिंवबद्धिंपत्रूयूनतस्यकायनिपत्रयकिंश्चिन्यनकृनपूसिमनयकृतोंस
नदवाञ्छीगमथलोषिषूनभान्दुवृहृशनतगमवलायानभाम्रुसत्यंपकासकामूनोसत्यंपतिथायपजाय
मावसासदवकार्यासहृनाहृतुमनसवित्तवानाकेनगावक्त्रामद्गावक्त्राऽङ्किंथकृताश्चसिसूलाषी
नाञ्चयंविद्यामहाताहृमपमदनिविद्यामहृपवक्त्रमिदावकाभंहिंतंकसिावृहृविनम - स्कामाधर्म
लाजसूलकरोंयनपथमनविद्याजम्यूहिंपत्रकाभिताधमायवविलोक्यसंघायवज्रोर्लमाावृ
त्यपादावदित्वावक्त्रावचनमवविनावृहीःपश्यकवृद्धास्ववूमानांश्रावकावधाऽऽषयाशाकयासावया
वत्यादवनायिचाञ्छगानन्यशोकात्रासवंत्रतेसमूद्धिताःसनिहसाज्ञासाधासागहृहृक्षामहामूनोस

क्षानरूपिचक्षुर्नाम्नि मक्षाचक्षुर्दिशीयासापूर्वोन्नजायतेयासाङ्गेनानिथतिनलनालिपत्रीयाघ्राणसंपन्न
कर्त्रिरूपेदियापूर्वविदेहविनाशनिकलचंवास्वदुदानिष्पन्नगलयाचत्वीजायतेनविशत्यक्षोनानानिर्ग
क्षानारक्षास्यलाकनाथशुक्लहिमानमरूक्षोरूगलाजोसक्कदापत्मालधिकामारूकाशामिकाचैवकामिनि
चैवतिरथापूर्वनामारूनदावशाकूनिकगृपानिजाामूखमलिकासेवाचवचंतेसर्वमदिनिाघ्रागला
पचदशदाचकानींयेकलावक्षेलक्षनसूयानियथावद्धनिदालकानामरूकनगृहितस्यचक्षूषिपत्रिव
कृकामृगलाजगृहितस्यक्षुद्रिलवनिदालूनाालकदनपत्रहीतमुहीतमुस्कक्षवासेनिदालकाश्रपत्मालगृह
हितमुहेनेलालाक्षमूरूकिामूषिकापत्रहतमुमूषिस्वक्षानेमूरूकिामारूकालगृहितमुस्कनेत्र

जकायवनरूसिस्यापथर्दीअरूक्षावगारूवनेरूनरूदिविनदिमूलविगिलिगवलिगलूनिभवूनिगीविलावले
लाचनीलाषनीपत्मलनीअलरूहारूगावीअलरूहानलहोयकर्षनिस्यहाक्षिपत्रेनिथगीगहालम्यग्वर्कुरूदिया
गहलक्षासूषिनीहारूमावनभ्रमुकजातकास्यरूसतिथगागहाकालेनपविमूचतुनानालक्षानिसूताभिः
अक्षनालमेसत्सर्षपाग्रयासक्षातनास्यनाविर्लिवंतुदालकानगोधमलासवरूक्ष्मावियामूदारूलेनालक्षि
कहवतुगर्हीसूर्षमादतुदालकास्यापथर्दीवोधिवोधिमक्षावोधिवोधनूमनेनरूसिनिवरूरूसेोसिक्षसिक्ष
सासवगेादूलासदेादूलागमानुलयाकाशूलवगेालूगारूगमरूलरूगीनिनिवासनियस्याहाागगेागलाप्रकदत
सवदासूषिसाक्षिनानमरूक्षोगेलिकलालोकथंनासमकूवनायरूदनगासेतूगमनवायदिवागरूक्षानान

वासामनिष्यनियतत्रिक्षसूक्षाषिर्नाञ्जनवत्यकनिष्ठाभायश्चनवमकामूनोमवायद्विवागृह्यानभाकुमावनवू
क्षायनमावश्चनेसिद्धानुमैनयदाक्षासयैनुङ्मविधीवश्चामनून्यनुस्याक्षाञ्जथवैसवणमक्षालाजाश्चका
समूर्क्षासंगंकुस्वाराजसिकावनन्नमस्यनवाचाकम्बिल्दनगर्वंश्चावकन्दैमक्षासाकनयमद्रनीसूत्रमूगृ
ह्यिद्याक्षासयैक्षावयदसयस्यस्यैवाप्रूयाक्षुनवाक्षुगृह्यहियागाकसनियास्वैस्यपूजायंसेनक्षविनथौञ्च १२
क्षम्बीवनुर्दंश्चांपश्चकुदंश्चांचपक्षमाणादासवैरूपूजाकुस्वाविद्याञ्जावनीयिनव्याथम्यीवस्यासामक्षासाक्षा
नांपूसत्रास्तमन्वाक्षसंक्षितानामवार्यीषयतिस्वनुर्दंश्चांस्यंयमवबनुनामाक्षासाजिपूसनास्तमन्वासक्षतिनाम
वाश्चषयतियंचदंश्चांस्वयमवबस्वासामक्षासाजानाङ्मासावकमक्षासाक्षयमन्दुनिसूतंयस्यायिगृह्यकम

ब्यनिदंसयिनिवाचयतिपर्य्यवायानिनत्यंचरुदनक्षगावन्वयंचस्वासामक्षासाजानवीवसयिदयातुमयनास्त
नास्तनपस्यंयक्षेषकुपलिस्काबैसोसूक्तंकतिव्यामासकुनश्चरुविधतिस्वस्वागतूकुनथम्मानिनपूजि
तंसाक्षांसाजामानानांचरुविधतिश्चन्यतिथिकिवामनयतिवाजकाश्चांपूक्षाक्षविधतिमिनामिनमध्यगो
यित्तकुनाक्षविधतिकुनचत्वार्क्षुन्दकुनयुतनवाकुत्सदक्षिणावाशुचिनाक्षविनथौ॥शुचिकायनशुचिक्षाक्षुत्तन
गयनास्तनापकुतनविक्षाषनाक्षुनकुदंसताक्षनशृकुदंसामिनंसंगाशानकुदंसवाशपयुक्षुनक्षविनथौ॥यस्य
चरुतनाक्षगृह्यिनस्यपूलनक्षुदंमक्षाताक्षपमन्दुनिसूतंसमावधिष्यति॥नस्यैवस्वासामक्षासाजाना॥स्वयमः
वलक्षावस्तनगुयिंसंविधास्यति॥एवंमक्षर्क्षिकुक्षुदनक्षगावामाक्षासाक्षयमन्दुनिसूतंयस्यायिगृह्यकम

पितामहोदिवार्कस्यधिष्यति॥तस्यसवत्सचायावदमनूक्षावतारंनसरिष्यति॥नमस्यमिवरुविष्यतिस्व
हृगानस्यय॰॰नीमहासादृपमदनिसूतधासधिष्यति॥तस्यकाक्षक्रम्बोसोमाहासाजानामूषमूपद्रुतीधि
ष्यति॥किमङ्गपूनश्चित्रंयक्षसाक्षसा॥तत्रकस्यहेतोयकंविसोकंविधीसंविदधति॥सत्वानीहितोप॥मञ्ज
मानिमत्रमुदानिनुस्रवलयवलहाकविसिक्थलमानिगोक्षीवधासधिसधासाविपूतापमानानि॥दूतावगास्नाअस्तान
मय॰॰यंवमनूदा॥अथदसहनाङ्गदेवराजसचिवपि॥पालिस्थनमस्त्वाशकनाथसमवित॥शुक्षाधिगा॰॰
यंविद्यासर्वासोकहितंकसि॥विद्यासहंपवक्ष्यामिनौषधीसमायूत॥क्षिसिषेपूथमयामागमासगकाक
लासेलयभद्रमङ्गिष्ठाशूकरीमुकनयाज॥पसिपसवालसंविसासानकंठगासंवृसा॥चदनावलकंकूष्ठनवं

पर्णकद्रवसा॥पिपंगुलोचनास्थकासषपाचमनस्त्रिसा॥स्वचंकुंकुमंहेगुमंसंयूतंवर्णकं॥प्रवाकसंयू
कावल्लिसवगहविभावनि॥सर्वहनविकासेषूप्रधानंतीजनेस्मृता॥गृहितायनमूत्रयतिहृतपजासनेस
सोमहादृकंषूसेकयंमतावेद्यतएवचयाहिपशुधृतिस्मनंहृतेस्नानहयत्र॥स्नानमृत्तिहृतानीनान्य
षामहितेषिनीगहसीसंखन्दगनिपनवांश्चपिसेपयत॥यावकयतिमद्यास्यतस्नेहृतमगुसा॥पक्षानी
सोयदापिपक्षिनीग्रमचाविभी॥यद्यतस्जोदिशंवापिदिगन्तसीस्नंनैर्ऋतहृतानानान्यषामहित
षिभीऽस्तद्रदनजागषूपक्षिपयत्रतत्रवा॥स्मनाम्याजनंनसैस्त्रिगमत्रिरुविष्यति॥स्रायिगमनिपाचषू
पस्त्रवकसमागमा॥सर्वमनेषूफर्यस्त्रिनाचाहिलिष्यति॥गलगण्डूचार्षषूवेमप्यधिष्ठकषूवा॥विषद्र

कूविषपित्तपीक्षिप्तंपमूर्च्छनं॥ अकनत्पयप्रासर्वकास्वार्दकृदनं॥ विवादार्क्लीलनंसिंहनाजदालविभाचनं॥
अस्सिंहिंसिंहिमाकानिंव्यलक्षमनिस्वस॥अपूतोलतंपूतंनिधनोसरुंत्रधनं॥यावंहिंघावतस्मनंमतान्य
तानिस्तावयतंनियंस्थानिगंतनेवदक्षमूलरुंवेषूच॥विघावस्यपाहुस्यंश्वानिकर्मकरंशुहं॥तनमतपदा
यस्किंहंदस्यवचनंयथा॥स्याद्यथर्दं॥अकनविकमस्तूयाषस्तूतंश्वमदंहनिधवसेवधवेदधिनिमूख
खूखूमखखसालगम॥वदवपवेहसिमहसेहालिनिस्वाहा॥स्तवीपापस्यंश्वस्वाम्मुमनसपतिवासस्या
स्वत्तस्वानाचस्तवदिग्विदिग्रुस्वाहा॥निहंतानिस्तवपापानिस्वाहा॥नमोवक्राचणकंसेशकपासानंहस्य स
यक्षसेनापतये॥सर्वंहासिंहिवस्तपूनिकाश्रकवागकस्वलाश्रयंचस्याश्रीदूता॥सहमसूर्य्यंयश्चनपूर्वदप

हास्यसा॥सदेवनानूषास्तूसेशकंसदृनंहनविघ्नं॥अचिंतिंशंहपयुक्तावयंहसाहसमर्दनं॥साक्षपमावः
निनामविघावेसाक्षपालनी॥नस्तासाहमकंसेकंलक्षावेसूतमूर्तिनं॥नमंहपूसूखविस्तनमंपूसूधाकम
अजसिंहनमस्कृत्यानंवानस्यविषं॥अथषसूरंगवासयाद्रकासत्तमयपंतंसूयनाद्यूस्यंहिंहुना
मामतयामास॥उश्रूद्धीर्ध्वंहिंजवोंसासाहमयमदूनीनासूतंभास्तनयं॥दंगयंतकावयंतपयंवोंप्रवंत्रभं
नंहविघ्नंति॥सदेवकस्यसाकस्यदीयंसानमधर्म्यंहितायसूस्वस्यंगविहासतायें॥यांकश्चिद्दिक्षवामंत्रभव
वक्त्रंतनमस्तासाहयमदनिंहुंतनंहुंवृक्षस्यापिपसितानीवधियास्यंसिंग्रहंतस्यंयतयूंस्यरुंतानिजाय
लनंकिमंगपून॥सविक्षानस्यकायस्यश्रंयंत्रवूवंमकविघोकनं॥वंमंत्रंत्रंहिंक्षवाहंगवंत्रंमंदंवांत्वंत

हनस्यपत्रपूष्पफलानिजापनस्किमगायून॥सविक्लानस्यकाथस्यश्रपणपूर्वमक्षिवियाकेन॥प्रवमूकेनक्षिक्ष
क्षेगावानमत्रवावत॥यानिमानिरुद्रत्रुगवतायक्षमहातेक्षाशुतोनिरीक्षितानि॥स्वायथदं॥महासाहमपन
दनिमक्षामायूसीमहाभागयशी॥महापनिसत्सा॥महानंगानूसालिनिवनि॥तानिरुद्रत्रुगवताय क्षमिषयसी
वक्षिनेनानूक्षानानिभासयितुं॥यिनूपात क्षक्षोजनंनिश्रयवक्षानूवाकृता॥अस्य क्षक्षगवंधिसुपातंपक्षे १५
मिषयसिवक्षितं॥छदमवहनतंयदिदंप क्षमिषसंहरंतत्रवयंरुद्रमहनकंथंपियथान॥प्रवानू
त्रुगवांस्तीक्षिक्षनेनदवावत॥त्रुनरिहिक्षवायाक्षनेममहासाहयमनदनिशुनभासयिष्यति॥वावयिष्यति
नेनाक्षनेनेयंभासनिशामसक्षाभासक्षाभावयितव्या॥त्रुनयिनुपात्रंगृह्णता॥साहावेयनिकृत्तंक्षास्यादयित

क्षा॥पवावत्तंक्षादूवश्रनास्तंक्षास्यादयितव्या॥प्रवंसवत्तंकृनेश्रनिक्षतक्षा॥श्रमिहादा॥वत्तंक्षाकृतप
क्षमिषानिकृत्यवाप क्षमिषानि॥कावायक्षमिषानियसिहोक्षेनेना॥किंतत्रकूटस्वसखानोपस्थय
नेनतत्रवाक्षासेय क्षमिषंसंतत्रदंसंक्षाकस्तनीया॥श्रमतक्षाश्रथर्म्यावतुदठर्पावलाजगानयोस्तूतानयोषु
वितयाहृषितेयाहोलागावूक्षयाय क्षमिक्षायदुपसिमृदितया॥साहित्रकंसूनकंचतुर्मुनंकालयि खामनध
सेनविवाक्षमारयितव्या॥गक्षीकृत्वावत्तस्तनकंहाजनेयादूहवनि॥तच्चपाओवंधयिखावाच्यं॥वाक्षनेवि
पक्षेनक्षक्षसिंहस्यनाथिना॥सविषंगिरिशिगुकेनहाजनमूपनासिनं॥तुनिरक्षनत्रशक्तानिविषिकृनहो
जितं॥प्रनेनसहयवाक्षनश्रमनंहवतुजनं॥विपक्षिनादवतायाः॥सिविनाक्षतुवत्तथा॥कक्षुछदपसन्ना

स्वदेवतायामावाहनं॥ कनकाख्यस्यदेवदीक्षितकाग्रचापस्तनाग्रस्कंधिदस्यवक्षदाग्रिदेशग्रवतांचक्षा
णाकर्णावसाक्षनासिकदानदेशसाक्षस्तीचमतांकासिचबुचबुकसिनीतथाकूर्दपूर्ववर्णवक्त्रयसिंहद्रतु
मनाहरसिंहितां॥ पूजितास्त्वाऽनेसाश्रतुरंगजनोपश्रमिषतसंस्तूयमस्तंस्तूयकरातुमापंचामिषत
संस्तथंसवर्तुंजामिरंगजनोसवंषावीजंगमनानोपनिथपाथिवीतसास्तंविरंगजनसंस्तूयमानसंस्तूयंकरातुम
स्तिन्नदुग्धंयथास्तूतंतादृशंस्वनपूनातथरंगजनसंस्तथंअसंस्तथंकरातुमास्याद्यथर्दा॥ खखमखखख

वर्षशतैरपगच्छतु तत्तदासन्नं हि खलु मम तपदाः स्यात्॥ ॥ एवमस्तु मकस्मिन्सत्ययरुगावानभव
स्त्रीभिरुतमस्मि॥ जेतवनेऽनाथपिण्डदस्यारामस्य कृतात्क्षुत्पीडनमार्हमनेकैर्वाधिस्त्वमहासत्त्वैः
कृतिनखलूपनामयनश्रवस्त्यांजेतवनेऽनाथपिण्डदस्यारामस्वातिनामक्षिप्रयतिवसतिस्मान
वादद्रुलूनाग्विलापवर्णोग्विलापयनाग्विलागतङ्नमस्मीविनयंसंपस्यार्थजिगाकदात्निकृपाद्यमा
नाश्यतमस्मात्युतिदात्क्षुधिसंनिकृमम
कृमकङ्कुमयनिदाक्षिनेपादाङ्क्षुदथमक्कालकायाकृमापतिनःकृनंवादयक्षिनीवपसिकृयमानाश्यपि
तिनस्यादृगावकथंपतिपद्यमश्रवंनेकृगवानायूषमतमानदमिदमवावागच्छत्वमानदमथान
तत्यवचनेऽरनुयामकामायीविद्यास्त्रीनथागतकाषिनवास्त्रनक्षिक्रोसङ्काकूसुगुर्किपसितानंपसि
गदंपतिपास्तनंभनिस्वत्यायनंदजुपसिहास्तंथामकपसिहाचंविदूषनंविरवनास्तृप्तिमावधत्व
नीवधकेकृत्यादवमहागोनागहागोरश्मूलग्रहागोमचूनग्रहागोगसूडग्रहागोगंधर्वहागोकिनरगहागा॥

यक्षग्रहान् पूतनग्रहान् पिशाचग्रहान् रेवतीग्रहान् कूष्माण्डग्रहान् पूतनग्रहान् कंदपूतनग्रहान् स्कंधग्रहान् उन्माद
ग्रहान् कुंभापस्मारग्रहान् शकुनग्रहान् रुक्ष्यक्षमनखार्द्रकिनलनवनाजाचिंचषक दू
सुकदूरुद्रिनदूस्मयादू॥ पूतनितदूसिंघिनदूसेंधिनावधूतान॥ नसादकाद्विद्वेतियकाचैतियकाचतुर्थकास॥
काहिकाश्चयमासिकीमासिकादर्वसिकामोद्वेत्रिकानित्यज्वरासानूत्यज्वरसानानूत्यज्वरसाद्वात्रिकाश्लेष्मिका
रुक्मिकासान्निपातिकासर्वज्वरान् सिंहावलिमयपन॥ भृंगीवरुदकनलाचकंसक्षिगंनासासागंसूखसार्ग
कथसार्गं हृद्रोगीगतग्रहं कर्णशूलं दुनसूतं हृदयशूलं पार्श्वशूलं वर्थसूतं उदयसूलं मनिशूलं गलुसूलं
वस्तिशूलं मूत्रशूलं वंशंयासूलं हसनसूलं पादशूलं॥ अगपत्यकल्पसूलं वापनय सर्वान्त्वस्त्रिदिवास्त्रिमः

आदिनोस्त्रिवास्त्रिसर्वमङ्गलानंसर्ववृद्धादिसंतुमे॥ तद्यथा॥ ॐतिविंतिकंतिहिंतिमिंतिपिंतिनि
तिमंत॥ मादूम्वासातयातनातदूम्यतहसिनिवसुसिहवमेतिवसुतिपीतुपिसाचिनिचष
निसासादिनि॥ ब्रह्मामसात्रलैमसेकलैनिरैमसेशतिविनिविनिविनिविनिति॥ ज॥ मसेर
तिमिनितिनिमरदूमरतिमलेस्दूमरुंदिमिदिविरुवावरसविमलहरसरुंबमूषिकानिर
कलाविमलाकासिंपकिंपूंकिसिंकूलवहलूरकोलहलूरवहलूर वासादूमादादूवादूमदूम्वा
एमलायावलायाम्रसिंवलायाविंशुंदिसिरमिवीरनिसिरहिविस्वूलवलवूरवूलवूलवूलवल
वूलवूलवूल॥ १०॥ मूहमूहमूहमूहमूहमूहमूहमूहमूहमूहमूहमू॥ १०॥ हहहह

हूं हूं हूं हूं हूं ॥ २ ॥ नागसैरसरा ॥ हूं ख सरा नसरा नागसरा हूं ख २ विग २ ख सूर २ गुसर २ हूं ब २ जि २ नि २ वे २ नि २ अ २ ग
ग २ त्रा २ मसा २ ॥ ॐ सिद्धि २ सि २ म २ सा ॥ ॐ सि २ नि २ क्ति २ सि २ नि ने ॥ ॐ सि २ द्धि २ सि २ नि ने दु २ दु २ भ्वा ने २ ॥ ॐ ने २ ग २ म २ सा
या २ व २ सा या २ व २ य २ सा २ वि म २ सा ॥ ॐ दि २ सि २ दि २ सि २ सि २ दि २ सि २ ना नमो वृक्षानां सिद्धि २ सि २ ग २ दा २ दि २ का २ ना २ म २ हा
हा २ स २ दा २ स २ व २ र्षु २ दे २ व २ त्त म २ नं २ द स २ स्र २ दि २ सा २ स २ नमो वृक्षानां स्वाहा ॥ अ २ थ २ स २ मा २ ख २ स २ ना २ य २ वि मू २ क्ष २ स्व २ हा
क्ष २ मे २ न ॥ स्व २ वि ष २ य २ न २ नू २ षा २ क्ष ॥ ॐ ना २ नि २ च २ म २ न २ य २ दा २ च्यू २ दा २ ह २ नि २ स्सा २ न २ नमो वृक्षाय २ न २ मो २ ष २ धी २ ना २ य २ न २ म २ सं २ या २ यी ८२
न २ म २ स्त २ च २ ना २ व २ रु २ षा २ या २ न २ मो २ मा २ क्षा २ मा २ यू २ थे २ वि २ षा २ सा ॥ ॐ ग २ ध ॥ सि २ द्ध २ स २ सि २ द्ध २ मा २ त्रि २ मा २ ब २ लि २ मू २ क्ष २ वि २ मू
क्ष २ म २ सं २ वि २ स २ नि २ म २ ङ्ग २ रु २ प २ रु २ मं २ क्ष २ म २ मा २ ङ्ग २ स्य २ हि २ त २ ल २ ग्ध २ हे २ ब २ न २ स २ र्षृ २ गा २ हो २ म २ कु २ रु

अ २ स्य २ कु २ रु २ मू २ वि २ मू २ ना २ व २ नि २ वि २ मा २ व २ नि २ म २ च २ यू २ म २ ज २ वि २ त २ ज २ य २ रु २ ध २ नि २ वि २ म २ सं २ म २ म २
न २ व २ र्ष २ नि २ म २ म २ सं २ म २ सि २ नि २ व २ ङ्क २ व २ न २ स्य २ च २ पू २ रु २ पु २ रु २ मि २ ना २ स्थ २ म २ म २ ङ्गा २ म २ म २ न २ सं २ व २ सि २ नि २ श्री २ रु द्र
व २ द २ च २ द्र २ य २ हा २ स्य २ सं २ य २ का २ नी २ ल २ य २ स २ व २ न २ व २ ङ्क २ ग्री २ षा २ व २ ङ्क २ ङ्गे २ थो २ स २ व २ ना २ य २ नि २ हू २ ने २ लक्ष २ मी २ ख्या
हा ॥ नमः स २ व २ वृ २ क्षा २ नां २ स्थ २ लि २ व २ नु २ म २ न २ स २ प २ ल्लि २ वा २ स्य २ स २ व २ सि २ ख्या २ ना २ व २ लक्षा २ कु २ वें २ ङ्गु २ दि २ प २ सि २ का
नें २ प २ लि २ ग २ हे २ प २ लि २ या २ स २ नें २ स्था २ नि २ स्य २ स्य २ न २ दं २ नु २ प २ लि २ हं २ ग २ म्फ २ प २ लि २ हं २ वि २ दू २ ष २ नें २ वि २ ना २ स २ नें २ सि २ मा २ व
ध २ ध २ स २ नि २ व २ ब २ व २ कू २ ल २ व २ नु २ जि २ व २ नु २ व २ र्षु २ ठा २ नें २ प २ ण २ नु २ स २ ते २ का २ सी ॥ न २ ध २ ख्या ॥ हूं २ वि २ ष्णु २ वि २ मू २ वि २ स्था २ ता ॥ नमः
स २ व २ वृ २ क्षा २ नां २ स्था २ ता ॥ स्था २ ल २ न २ य २ न २ सा २ न २ दा २ न्य ॥ स २ ङ्ग २ न २ का २ स २ न २ नें २ स २ म २ य २ न २ स २ व २ ना २ व २ रा २ सा २ ना २ म २ म २ यू २ स २ सा २ ग्रा

वस्त्रवासस्त्वा व्यानदमहामायूयीविद्यासाक्षाद्दर्शयामि॥ॐसिमिसिमिसिमि
सिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमि

वा.अस्रश्चिवा.अस्रस्तपूवा.अस्रसदूहितावा.अस्रसहस्रकोवा.अस्रसमहत्तिकावा.अस्रसपार्षदावा.अस्रपार्षदिवा.मसूनावा.मसूनिवा.मसूनपूनावा.मसूदूहितावा.मसूनमहत्तमहस्रकावा.मसूमहत्तिकावा.मसूनपार्षदावा.अस्रसेपार्षदिवा॥गसूजावा.वागसूनीवा.गसूनपूजावा.गसूजदूहितावा.गसूनमहस्रकावा.गसूनममहत्तिकावा.गसूनपार्षदावा.मसूनपार्षदिवा॥गसूजावा.मसूजिवा.गसूनपूजावा.गसूनदूहितावा.गसूनमहस्रकावा.गसूनमहत्तिकावा.गसूनपार्षदावा.गसूनपार्षदिवा॥गधजावा.गधजीवा.गधजपूजावा.गधजदूहितावा.गधजमहत्तकावा.गधजमहत्तिकाकावा.गधजपार्षदावा.गधजपार्षदिवा॥किनसावा.किनसिवा.किनसपूजावा.किनसदूहितावा.किनसमहत्तकावा.किनसमहत्तिकावा.किनसपार्षदावा.किनसपार्षदिवा॥मक्षासगस

वा.मक्षासगिवा.मक्षासपूजावा.मक्षासगदूहितावा.मक्षासगमहत्तकावा.मक्षासगमहत्तिकावा.मक्षासगपार्षदावा.मक्षासगपार्षदिवा॥यक्षजावा.यक्षीवा.यक्षपूजावा.यक्षदूहितावा.यक्षमहत्तकावा.यक्षमहत्तिकावा.यक्षपार्षदावा.यक्षपार्षदिवा॥राक्षसजावा.राक्षसिवा.राक्षसपूजावा.राक्षसदूहितावा.राक्षसमहत्तकावा.राक्षसमहत्तिकावा.राक्षसपार्षदावा.राक्षसपार्षदिवा॥पजावा.पजिवा.पजपूजावा.पजदूहितावा.पजमहत्तकावा.पजमहत्तिकावा.पजपार्षदावा.पजपार्षदिवा॥पिसाचजावा.पिसाचिवा.पिसाचदूहितावा.पिसाचमहत्तकावा.पिसाचमहत्तिकावा.पिसाचपार्षदावा.पिसाचपार्षदिवा॥रूजावा.रूजिवा.रूजपूजावा.रूजदूहितावा.रूजमहत्तकावा.रूजमहत्तिकावा.रूजपार्षदावा.रूजपार्षदिवा॥कूष्मांडजावा.कूष्मांडीवा.कूष्मांडपूजावा.कूष्मांडदूहितावा

कूष्माण्डमहत्तिकावा कूष्माण्डपार्श्वदिवा कूष्माण्डपार्श्वदिवा॥ पूतनावा पूतनिवा पूत
नपूतावा पूतनदूहितावा पूतनमहत्तिकावा पूतमहत्तिकावा पूतनपार्श्वदावा पूतनपार्श्वदिवा॥ कटपूतनी
वा पूतनिवा पूतनपूतावा पूतनदूहितावा पूतनमहत्तिकावा पूतनमहत्तिकावा पूतनपार्श्वदावा पूतनपार्श्व
वा॥ कटपूतनावा कटपूतनपूतावा कटपूतनदूहितावा कटपूतनमहत्तिकावा कटपूतनमहत्तिका
वा कटपूतनपार्श्वदावा कटपूतनपार्श्वदीकवा॥ स्कन्धकवा स्कन्धपूतावा स्कन्धदूहितावा स्कन्धमहत्त
कावा॥ स्कन्धमहत्तकावा महत्तिकावा स्कन्धपार्श्वदावा स्कन्धपार्श्वदीवा॥ उन्मादावा उन्मादिवा उन्मादपूतावा
उन्मादूहितावा उन्मादमहत्तकावा उन्मादमहत्तिकावा उन्मादपार्श्वदिवा॥ अपस्मारावा अपस्मारिवा

अपस्मारपूतावा अपस्मारदूहितावा अपस्मारमहत्तकावा अपस्मारमहत्तिकावा अपस्मारपा
र्श्विवादावा अपस्मारपार्श्वदीवा॥ उष्कारकावा उष्कारकिवा उष्कारकपूतावा उष्कारकमहत्त
कावा उष्कारमहत्तिकावा उष्कारकपार्श्वदावा उष्कारकपार्श्वदिवा॥ उपसेकमित्यनित्यवत्ताधिश्र
वत्तारगवधिश्रवत्तासनसंहिंस्यतिं॥ तस्यावत्तासत्वा श्रासम्बत्तस्वा श्रथोपसेकमित्यैश्वत्तासाधिश्रव
त्तारगवधीश्रवत्तारगवधीश्रवत्तावनस्पतिं॥ नदवाह्रवस्तमियस्कन्नीं नागनागस्तमियस्कन्नीं॥ना
हसाश्वस्तस्तमियस्कन्नीं॥ नगस्तूपागस्तूपस्तमियस्कन्नीं॥ नगाधगागाधवीस्तमियस्कन्नीं॥ नदी
नसाक्किनस्तस्तमियस्कन्नीं॥ मद्गुरागमद्गुरागस्तमियस्कन्नीं॥ नयक्षयक्षस्तमियस्कन्नीं॥ नसाङ्गस

समितीयन्नानयज्ञायतनसमितियस्त्रुनानयिज्ञायस्समितीयस्त्रुनानस्त्रुतनसमितियस्त्रुनंन
कूल्लाणुकूल्लाणुसमितीयस्त्रुनानूतनूतनसमितीयस्त्रुनानकट्यूतनकट्यूतनसमितियस्त्रुनं
नस्कंधसमियस्त्रुनंनासादऽमादसमितीयस्त्रुनानन्द्रयाश्छयसमितीयस्त्रुनानपसमासपूत
स्त्रयसमासमितियस्त्रुनानजाल्कासक्कालास्कसमितियस्त्रुनानसस्त्रिथ्यतियस्त्रेनांमसाविद्याक
सिदलिकमित्थतिसक्कथास्यसद्दृत्म् ध्रुंश्रर्जिकस्यत्वमश्रस्त्री॥ॐमानिवानमत्रुयदानिकमसिक
स्त्रीथानि॥नयथा॥ॐसिमिसिकिसिमिसिकिदूगक्षामूकस्मकै॥श्रोढनाऽस्त्रनाऽवर्षतुदव॥यस
माऽकक्यीयी॥श्रोसावासासमदाहिकाऽॐसिमिसिहिंसिकाऽदकाऽदकाऽॐसिमिसिमिऽॐसिमि

सिमिसिमिसिसमनऽःकृत्वा॥हस्रहिंसिरमिसिरविसिरकिसिरगार्घनिवधी॥चूस्रूस्वस्रश्चिसिरचूस्रश्
चिरुश्रसिरिवरुछिंदिविद्धि॥खिखिखिखि॥४॥रुहरुहरुहर

विषंश्रनविषंसर्ववृक्षानांगंजन॥रसरसरसकं॥चलचलकं॥वसनाविसिविसिहनम्विषंविहनम्विषं॥नाम्नि
विषं॥सकानींसत्यक्षंवृक्षानींसप्रवकसंघानींगंजन॥प्रसामसाह्वसिमसानिसिमसारंहिताद्रुहानि
सिमानिमाह्मादुमाधूमाधूसकूक्ताःसम्वातुम्वासमतुवाश्राढनाढनिसकूह्नादाधवर्षतुदवाह्वसिकि
सिःसमंतननवसामादसमासनि॥मद्रीमसर्वसर्वषूवूससवूससनि॥वूदासिनिवूससिःकवढंकवनकमू ८८
लेंह्नसिसवस॥तुम्बतुम्बप्रियंकसंश्रावहंपसिवहंनवादकनवर्षतुदवसमंचवसंखक्ता॥नमाहगव
गंह्नदहाःमिसिकायाह्नंदिनयहाःदाहिकायीं॥हंह्नासिकाय॥श्रसेनसैनसेकृतसभ्रदनहंश्रासनैयाः
सनैयापनिकूसे॥नमाहगवेतुवूक्षानींसाक्त॥श्रहाकमाज्ञिस्यजिनाविषंश्रीःसिखीःसिने॥पूनुसिकः

कस्यमूसाःश्रमसस्यमूसंडपगम्यविल्वजुकासिसीषमूसंककूहंदवाक्षनाःवूहंस्यक्षानामम्निंडहं
म्यसांस्यंसमंवमूसंडपगम्यकाग्रंपा॥सूस्यहंमूसंमिनिमंक्षपूगवा॥उपस्यवाधिंसमवाश्यसौम
मा॥प्रनषूवृंछषूमहंछिकषूयादवतासनिश्रहिमनाःनादवतामूदितमनाडगम॥कूवंतुसानिंह्नसि
वंवनिर्यं॥मनसंवयसिवासस्वसंवत्सरानाह्नंनथा॥ह्नंहिसिमिसिंकिसिंचिसिःचसिंकसिवासिंदूसा
स्तदूमादवूससवूससहंदकसंजमूसाःह्नंसिसवतःकूनाकूनासिनासायसिःपासायसिःपश्चसिःकंचिसा
वांतुसिःह्नंसिवांसिंश्चंतुहासिंजामनंपदाल्लाहंसंहसाःपूनसानंदमंदोषंश्लोवाक्षनासंहतापंसंहसिं
नाःगंकंपादवागमनामिंदसंचंतुहिंश्यमंहतासाजे॥श्रथाविंसिंहिंसिंवंसंहतापंक्षसनापंसिंहिंयाःक्षानंदं

मीसं नामषष्ठं कुमारषष्ठं कपिंदूथं विरूपं सकामकातफलास्यसरूटेनूश्रारंगकेरवमरुत्ती॥न
यथा॥ क्रिक्लिंमूलैश्चतुर्मूलेन ढेनढेकूसनाडा॥ॐनुमिनपालूहडा॥रसठका॥रसकामसकामस
नका॥ॐसिक्सिंसिगधहिकाडर्डुम्बमाहिनमडा॥नमावहानास्यक्लिवाहिपदरोडुस्यक्लिवोडुवडु
दस्यक्लिवोवडनामर्जस्यक्लिपत्यागनेषूवास्यक्लिसागास्यक्लिदिवास्यक्लिनक्षदिनाक्लिनास्यक्लिसर्वमक्षाला
ऽसर्ववंक्षदिठानुमास्तवनस्यक्लिवोरोनुमागवेषापापमागमनासर्वदिवसकस्यानंसर्वनिक्षनरुदका
सववृक्षमरुधिकासर्वंश्रुनानिसाशुयाश्रनेनसस्यवाकेस्यक्लिवनुसमनडा॥श्रमयामाहामायू
विद्यासाक्षनथगत्क्षधितयाममसपसिवासस्यसवसस्वनाकरसक्षांकुर्वंतुगुर्फिंपसिगा

गहंपसियासनंसानित्यस्तयनंदशुपसिहासंशमकपसिहासंविषदूषनं विषगनानंसीमावधबंधसनिवंध
कस्यासिद्धीवनुवर्षसनंपबंधनुमासवदासंनंस्याहा॥यत्रानंदयक्षामहायक्षा॥समूदकूसेपनिवसनिसमा॥
यत्रहमस्यर्वनताजंषूयत्राथषूपर्वतसाजंषूश्रटविषूमहाश्रद्वीषूनदिषूमहानदिषकूसनदिषकूलेषू
महाकूलषूपसवनेषूनडागषूपल्वलषू॥गिरिस्रुहान्मगनेषूमहान्मगनेषूवस्यसषनगनेषा
गामषग्रामषूवनषूपर्वनिषकाननेषूपथषूपथषू॥यत्रानंदयक्षामहायक्षा॥श्रडकवर्यांराजभन्यांय
सवनिसमा॥ॐयनयामहाना यूर्यांविद्यासाक्षमसपसिवासस्यसवसस्वन करसक्षांकुर्वंतुगुर्फिंपसिगा
नंपसिगहंपसियासनंसानित्यस्तयनंदशुपसिहासंसमकपसिहासंविदूषविषनोगनंसिमावधब

सनिवधधकूवकुजीवकुवर्षगतंपद्मकुसत्सदागतंनद्यथाहसिहासीनिवसिवासीनिगमनिगुमनी
माहनिस्मरुनिजस्मरुनिश्चयौंऽवस्त्वाहाऽपूर्वायामादैदिसायौंधनेलाक्षनामगधर्वराजायतिवसतिगागधर्व
र्वीविषयतिसनकागधवस्तसहनयसिवासगागधकानामाधिपत्यंकारयतिगयपूर्वादिसंलक्षतियतियासय
तिगासाधिसपूतसपोनसजुगानासामाह्यासससनायतिसपद्यसदूतसपवससपार्षदाऽश्वनयामहामापू २०
र्वीविषयासाक्षानमसपतिवासस्यसर्वसत्वानांवसक्षाकसाकुगुफिंपसिगानंपसिगहंपसिपासनंगमगिंस्यस्यनं
दनुपसिहासंसमकपसिहासंविष्कूषनंविषनासनंसीमावधवसनीवधकूकूकसाकुजिवकुवर्षसतंपद्मकुस
सदासतंगतंनद्यथावसुकरश्रुतनयातनिवसूनवतिवेजूमासिनिवसिनिपूतिकेशवूचिवूःस्माहाऽप्र
ष्ठिमायामानदक्षिसायौंविसूपाक्षानामनागमहासाजायतिसतिनागमधिपतिसनेकनागगतसहसप
तिवासानागमधिपत्यंकारयतिगपश्चिमादिसंलक्षतियतियासयतिसाधिसपूतासयानासजुकासमा

स्या॥स्त्र॒ स्त्र॒नायनि॑स्त्र॒ पत्वा॒स्त्र॒दू॒त्रा॒स्त्र॒यत्व॒स्त्र॒स्त्र॒यार्ष॒दा॥ॐ॒नयाम॒ह्रा॒मायू॒र्य्यी॒विद्या॒ल्ला॒क्षाम॒म॒स्त्र॒पत्नि॒वा॒स्त्र॒त्य॒स्त्र॒व॒स्त्र॒
स्त्रा॒ना॒ क्ष॒स्त्र॒क्षा॒क॒ला॒नु॒नु॒ष्टिं॒प॒स्त्रि॒ता॒नं॒प॒स्त्रि॒ग॒हं॒प॒स्त्रि॒या॒स्त्र॒नं॒ग॒नि॒ह्स्त्र॒य॒न॒दं॒नु॒प॒स्त्रि॒ता॒सं॒क्ष॒प॒स्त्रि॒ता॒सं॒वि॒ष॒
दू॒ष॒नं॒वि॒ष॒ना॒सं॒न॒स्त्रि॒मा॒वं॒ष॒ष॒स्त्र॒नि॒व॒ष॒ क्ष॒क॒ला॒नु॒ज्जि॒व॒नु॒व॒र्ष॒ग॒तं॒प॒ग्ध॒नु॒स्त्र॒त्स्त्र॒दा॒ग॒तं॥॥॒न॒य॒था॒ः॒स्त्र॒स्त्र॒स्त्र॒स्त्र॒म॒स्त्र॒स्त्र॒
स्त्र॒स्त्र॒म॒स्त्र॒स्त्र॒स्त्र॒स्त्र

ह्रासंविदूषनंविषस्यनंस्यनंसिमावंधस्यनिवंधस्यकूर्वंतुकिंवंतुवधंस्तंपश्चंतुसस्तदास्तंतांतथा॥प्रस्ता
वसामग्रिसिमस्ताःक्रमदूमदूमवधंतुदवस्तमनंनक्लसिमिसिंतुवंतुंचंजृंक्षपस्तमदूवंदृवधंतुंद
वंतुंतुंजापनंदवस्तांजृंतुंतुंतुंतुंतुंवूंकंमूंक्तं॥क्रसिंस्तिमिसिंमिसिंसिंदिंसिंरंसिंसिमिसिंतुंसं
तुंतुंस्वांतु॥उग्रंदंक्रस्वमानंदमहायक्षसनापतिनांनामानिंयंधस्तंभंपतिवर्तंतिंयंधस्तंनिंतांस २२
स्तांस्तंनिंपंस्तिंयांस्तंयंतिंतांतंपथाःक्रंक्षंपूंतंकूंवंस्तंस्वंसंज्ञयांनस्तंवाहनांनांसिंधिसांयांपंतिवर्तंतिंतां देवंस्तंथा
पयाचंक्रं॥स्तापनंयांमहामायूंक्रीविद्यांसाह्वांमनंसंपंतिंवांस्तंयंस्तंवंस्तंस्वांनांक्रंस्तांकूंवंतुंगंछंकिंयंस्तिंतांनं
द्रंसिंगंहंयांसिंयांस्तंनंतंभंसिंस्तंस्तंयंनंदंतुंपंस्तिंहांस्तंनंविंषंदूंखंनंविंषंनांस्तंनंस्तिंमांवंधंस्तंनिंवंधंस्तंकूंवं

स्तिंवंतुंपंधंस्तंयंन्धंतुंस्तंस्तदांस्तंनंधंस्तंथांथा॥क्रंसंरंवंसंवंल्लूंसंमांतंगिंवंजुंस्तिंपंस्तूंभंनिंविंचंस्तिंनिंस्तंमोंस्ति
गंधांस्तिंचंन्तुंस्तिंमांस्तिंनिंमांतंगिंक्रंसिंरंस्त्रांगंनिंकोंष्ठिकांवंचंनि॥विंक्रांस्तिंवांस्तिंमांक्रिंसिंरंमिंसिंकूंपंस्त्यांक्रां
कंकूंछंदपांदंस्तिंपूंतंक्लूंस्तांयांवंधंस्तांगिंत॥सोंस्तांक्रदपूंस्तंयंक्षंडुंलूंस्तांयांक्रंमांनवां॥वंजयांनिंस्तांजंगंक्रं
गंधंकूंटंकूंतांस्तंयं॥निंक्रंस्त्यांस्तंनूंपंर्यंनिंस्तांगंस्तांनिंवंस्तंक्षंसों॥मंक्तांवंस्तांमंक्तांनंजांदंस्तंयांजंनंविंक्रम
गंस्तूंजांविंपूंस्तांसोंविंमुंक्तं॥स्तिंनिंमूंस्तंस्तांजंगंस्तंक्रंवंकूंस्तांयंक्षांमंक्तांस्तंयांमंक्तांवंस्तं॥कांस्तांयंकांस्तंकोंयंक्षो
वंसंनं॥कांविंस्तंन्तुंनिंयंनंजांकांमूंनिंवंर्तुं॥ग्रंमंक्तंकंनंतुंमंक्तांमूंनिं॥कंस्तांभंयांदांवंस्तांयोंविंस्तांनंषूंम
क्रंस्वंस॥वंक्रंस्यंनिंभंस्तांवंस्यांस्तांकंकंनंस्तांगंस्तांवंसंनं॥वंजांयूंधंस्यंवंस्तांयोंमंस्तेषूंक्रंतिंपिंक्षंस्तांवांस्तांनेः

स्यामलाकालवयायाकुसदसन॥विष्कुयश्लोकासिकायीवसलभगलयासियी॥विष्णिवनस्कामपर्नुउ
सगमयीवमर्दन॥श्राट्यामादृवकायक्ष॥कपिसावहुभायकुडर्जीयचान्यस्पूतागवसहुमिस्व
निषू॥हलूकालूकहूषूनदानदपूसस्थिताश्लमदकमास्यवस्यादनदामस्पश्चागुकुदंडुस्तः
वाकुषूदनामावमस्थिलोमहागिसिगिसिनगसेवासवावेदिगवसनासाहितकुकाकिकयाकूमा॥
सासाकविष्णुनावैष्णानदस्तवानहाकसिगषूवहदथा॥दूर्यावनमस्पघूपूसर्कनवाहनावनामदनीमगु
पयक्षागिसिकूटश्चमासवाहदसवसाहितस्वषूसवहदभसाकनासादीसकयासिटकसाथवाहाधने
स्वस॥सस्तिनगयकूटदकूवस्हदावसांनिषूसिवशिवपूसाकासासिवहदभस्थिक्षाकून्दुम्बेदपूसे

यक्षापूस्यकेतुसिसापूस॥दासूकादासूकपूसकयिसावसनिवर्षुषू॥वक्षकश्यामानिहदपूनहदवक्षुकसा
पदमनभ्यगमभसनक्षसिसायीयहर्जीन॥खस्पाकोमहायक्षादस्तसस्तनिवासिक॥चित्रगुकाहनूमानि
वसालवषूपहंकस॥दिवर्हनवेवनगसनदिवर्हना॥वाहस्थीवपिसम्हुरंपाकुकस्हपियामि
कसायागस्कायक्षसंकायांकसगादस॥स्यस्यपिशायक्षागिसिमूशुस्वकागस॥विजयावजयतस्व
सतयाभूमाथस॥मस्यपूनकायक्षकसस्वकिनस॥यांपुषूमयमासीपतिथावषशुक॥पिलंगस्व
षूसंकासिनसक्षवसीसुखावदु॥नासिकस्हदसायक्षभस्मस्हस्तूकहूके॥नदिकावपिसानदिविस्व
कसहाटक॥सम्वादस्कसिङ्गषूकागस्याश्रमहाहज॥स्वस्तिकस्वस्तिकदूकावनवास्थीवपासका॥

ञिस्कधरुदकनाम्स्दापूरधनाधरुवेसानकवसायक्षश्रवणीयिपदस्तन॥ग्रामदनसिखनिवधेदि
सवा*लिपिय॥रुनाकास्थितकनिपूर्यामतंकमतंदम॥ग्रसकरुविसालाक्षश्रद्कसिउदुम्बरसं
श्रनाशगचकोगमचीसानिवर्षीविसावन॥श्रदिरुनवसितक.कंपिस्यकपिलस्थाःवकूवेसाऽग्निल
नायामशुचीपून्नुकस्थाः॥नैमभद्रासिया*स्यीपसशगशसाद्भया॥वसूनायीदृदवनूयाश्रयवपूर्ण ८४
ज्ञय॥कूलक्षनवयक्षदानवर्कुतसाकको॥यक्षिस्कागवनत्रैवनहालूखलमघसा॥यतियानस्वसिद्ध
श्रायनिवनिवासिन॥सिद्धायनस्थागाघ्रंस्कूसायीमरुसज्जक्ष॥यक्षीसिंहवसोयोनुसिंहव्याघवसा
वसी॥कादीवर्षमहासनस्थापसपूर्णंजय॥पूष्यदनस्यपायीनागवश्यमिसिवज्ञ॥ग्रमयाशयर्वरुप्य

क्ष.रसनश्वेवनागसे॥वीसवाद्रुवसाकरुकाकयीवसरुक्षावह॥कोसाव्यीवायनयासोरुदिकायीवरु
दिक॥पक्षयादृसिपूरुवनान्नारुतमूखस्थ॥श्रसाकस्येकवविषूश्रेस्वाष्ट्रावकदैकद॥ग्रसकरुवः
सिद्ध॥थर्मर्दनव्यग्निर्तंजय॥श्रसमदकमूरुकस.सधवमनिकानन॥विकटैकटाश्वयपक्षावसूनक
पिलवस्तुनि॥गाधासकानेकूत्रिकाशसकानिसयाकूव॥यक्षमव्यमकियपसोरुदयामहापसा॥वेसा
दृकदासपूसेजस्कुकानसरुमिषू॥पक्षादधदकटाक्काकास्थ॥विकटरुद्रयि॥वैमानिकादेवसमदिस
क्षूसमणुस॥यरुकस्यकसमिसेवदकवजटापूसे॥यास्थिकरुतिनाम्नातुवसकस्मीसस्थिषू॥यरु
पूनसतायस्यमशासत्यीतमावसा॥स्कथपूतयाम्विकत्वसवसनंविनरुषिमिषू॥स्कधाक्षरुदिनामन

नमुताकौशिकवसत॥उष्ट्रयादकसिंहमूषमनुसानुसासन॥तेकेचसप्तकाविंशतिनामिकानि
क्षिया॥धमयासक्षमासमूवाक्षीवेवनतानुज॥जिनर्षिकोराजपूतग्रीमावेर्णनानामउ॥यस्यकोटायसिंह
नमुखासेषूनिवसिक॥सातगिरिसिंहनवगवसमियूमासे॥तिनुसयानिक्रियूसेकसिंगषूयमदनी
यक्षसगनाहमिउसिंहसयूधनस्वस॥नुकामूषवानक्षीयाताशेकिकसेवसत॥यशस्वसयूनुसिंहसमि
सक्षमताषूसे॥यहंजनबुदसयूर्योगाकसिमवसत॥वचशवचशधनमानसिशेवकामद॥यूक्षिवि
सयवर्हकाविंशनुसकूवस॥यासतसयासतषूगकल्पनषूसकस॥धूमसिंगवाह्नीकनकषूवर्षिग
स॥यूनुवर्हनयूसूमयकसाउसावाक्षियानकी॥कूस्मस्वकसंसेयूमसयूकसक्ष॥विनसनक्षवाक्ष

नसमषूसामन॥यिगशवेवतासीनेयत्रीयविंयदस्त॥कूक्षिसयक्षासाक्षगृहविंयसिंसिमनि
वासिका॥हयहनसदमनयक्षानीयंयुयासयत॥ ॥तायीसमयासअसतकोअसकासूय॥नदिवनः
दनगसंगमसक्षेजसिंहिन॥दवावनसमवेसमन॥सहस्यंयसियासकपक्षकोटियसिवत॥अट
कवस्थीनिवासिक॥प्रसिद्धकायक्षमहासिंयामहवस॥यसस्तकुयमथनादूर्यिसंयसाशिना
॥सहिमगंयूनिमकवनवेत्रायसस्विंय॥देवास्तसमयिस्तंगमनमसनूहवनिमहयिका॥तायनव
सहामायूंयीविंयासाक्षममसयसियासत्यवसस्तानीं कसक्षीकूवंतुगुक्षियसितानीयसिगहंयस
यासनंभनिंत्यहत्यनंदनुयसिहासंतमकयसितासंविदूषनासनीसिमावभस्यसनिवव कक्वव

क्षिवनुवर्वीसर्वयक्षकुलसर्वांसर्वं॥यथा॥ॐकहकिकहसिनिकासिनि॥वसनिभासनिवसनाहकहवूरहू
हनहनहनहनहनहनहनहनहनहनहन॥१०॥ॐमिनामनम॥दहदहदहदहदहदहदहदहदहदहदहदहदहदह॥१०
ॐहिनवूलमनम॥ॐवयवयवयवयवयवयवयवयवयवयवयवयव॥१०॥ॐस्यथिकानमनमस्तयसिवास्त्य॥वू
वूवूवूवूवूवूवूवू॥१०॥नास्तयगनमनमगनयसिवास्त्य॥हहहहहहहहहहहह॥१०॥किहिकिहिकिहिकि
हिकिहिकिहिकिहिकिहिकिहिकिहि॥१०॥नास्तयगनमनमस्तयसिवास्त्य॥कहाकहाकहाकहाकहाकहा
कहाकहाकहाकहाकहाकहाकहा॥१०॥नास्तयगनमनमस्तयसिवास्त्यसर्वसत्वानाञ्चवूसवूसवूसवूस
वूसवूसवूसवूसवूसवूसवूसवूस॥१०॥हिसिहिसिहिसिहिसिहिसिहिसिहिसिहिसिहिसिहिसि॥१०॥मि

सिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसिमिसि॥१०॥हूलहूलहूलहूलहूलहूलहूलहूलहूलहूल
लय॥१०॥हूवूहूवूहूवूहूवूहूवूहूवूहूवूहूवूहूवूहूवू॥१०॥विहिविहिविहिविहिविहिविहिविहिविहिविहि
हविहि॥१०॥नास्तयगनमनमस्तयसिवास्तसर्वसत्वानाञ्चयवाहिनीविनाशिकमिकमिक
वूकवूकै॥ग्रहदमनयक्षिसत्यगर्भसमस्तदस्तवार्थसाधनि॥ॐसेकमसेविमसेचदयहासह
यीकाक्रुदूर्विरुयादूमदूयदादूमथियेकतसक्षरमीसयसिवातंसवस्त्वानीवसक्षीकूवीकुशिवकुवर्ष
सनयक्षकुलगतदास्तैश्चकृत्वमानदंश्चथविसर्जनीमहायक्षसेनायनिनाम्नामानि॥यदस्यदि
क्षसक्षनियसियास्तयनि॥पूर्वयामानदंदिसायांकृत्वसाहमहयक्षसेनापतयायनिवसन्ति॥ययूर्वी

दिसं रक्षतियसियासय ति॥ तद्यथा॥ दिशं रक्षन्तु कपिस्वति॥ कृष्णनयामहामायूरी विद्या सा
क्षामनसयसिवास्वस्तवस्त्वाना॰ रक्षां कुर्वन्तु दिशं यसिता नंयसिगहंयसियासनं सानिस्वस्त्वयनंद
नुयसिताखंसक्कयसिताखंविषदूषनंविनासनंसीमाबंधबस्तीबंध॰ कुर्वन्तुवर्षसतंपञ्चनुसतंदी
नांदक्षिनायामानन्दीसाया वस्यासामहायक्षसेनापत्यधिपतिर्दीयदक्षिनांदिशं रक्षतियासय ति॥ ८१
॥ तद्यथा॥ सिंहउपसिंहासंघिलादतिस्वति॥ कृष्णनयामहामायूरी विद्या सा क्षामनसयसिवास्वस्तवस्त्वा
नां रक्षां कुर्वन्तु दिशं यसिता नंयसिगहंयसियासनं सानिस्वस्त्वयनंदनुयसिताखंसक्कयसिताखं विषदूष
विषनासनं सीमाबंधबस्तीबंध॰ कुर्वन्तु शिवन्तुवर्षसतंपञ्चनुगदीसतं॥ पञ्चमायामानदक्षिनयाच

खासायक्षसेनापत्यधिपतिर्दीयपश्चिमांदिशं रक्षतियसियासय ति॥ तद्यथा॥ वरुणवरुणदंड
यागयासासाविद्यूसक्कति॥ कृष्णनयामहामायूरी विद्या सा क्षामनसयसिवास्वस्तवस्त्वानां रक्षां
रक्षांकुर्वन्तु दिशं यसिता नंयसिगहंयसियासनं सानिस्वस्त्वयनंदनुयसिताखंसक्कयसिताखं विषदू
नासनं सीमाबंधबस्तीबंध॰ कुर्वन्तु शिवन्तुवर्षसतंपञ्चनुगदीसतं॥ पञ्चमायामानदक्षिनयाच

ण नंविषनास नंसीमावष्टस्रा व ऋकूवंकुरिवंकुवर्षस नंयग्रंकुस्त्रदास नं॥ वस्त्रा सा ऋक्ष मश्रानदमहा
यक्ष सेनापतय यंयविदिसास्त्रपतिवस नंति॥ यविदिसां रक्षनिपतिपासयति॥ तद्यथा॥ पाश्चिक्ष्या ऋक्ष
स्त्रा ण्डा॥ स्कार्णिसिहेमवतश्चेति॥ तेषयामहामायूर्यीविद्यारा ऋक्षमनसपतिवास्त्रवस्त्रानांवरक्षा
कूवंकुरुकिंपरिवारंपरिगहंपतिपासनंभ्रमिंस्वस्त्रायनंदपुरहासनंसम्पतिहासंविदूषदूरवनं
विषनास नंसीमावष्टस्रनिवष्टऋकूवंकुरिवंकुवर्षसपंयग्रंकुस्त्रदास नं॥ वस्त्रा सा ऋक्ष मश्रानदमहायक्ष सेना
पतय यंयसंभ्रपतिवस नंति॥ यक्षसेनिगतास्त्रा ऋक्षनिपतिपासयति॥ हेमः सरहनः कासऽपकासयका
सकेति॥ तेषयनयामहामायूर्यीविद्यारा ऋक्षमनसपतिवास्त्रवस्त्रानाऋक्षरक्षाकूवंकुरुकिंपरिवारं

पतिगहंपरिपासनंभ्रमिंस्वस्त्रायनंदपुरहासनंविषदूषनंविषनास नंसीमावष्टस्रनिवष्टऋकूवंकुरिवंकुवर्षस
नंयग्रंकुस्त्रदास नं॥ वस्त्रा सा ऋक्ष मश्रानदमहायक्ष सेनापतय यंश्रवणीक्षपतिवस नंति॥ यश्रवण
सिगतास्त्रानक्षनिपतिपासयति॥ तद्यथा॥ सोमः सूर्यो मिवायूश्चेति॥ तेषयनयामहामायूर्यीविद्यारा ऋक्ष
मनसपतिवास्त्रवस्त्रानाऋक्षरक्षाकूवंकुरुकिंपरिवारंपरिगहंपतिपासनंभ्रमिंस्वस्त्रायनंदपुर
पुरिहासंरूपरिहासंविषदूषनंविषनास नंसीमावष्टस्रनिवष्टऋकूवंकुरिवंकुवर्षसनंयग्रंकुस्त्रदा
सनंतऽएकऋषमानदवैश्रमनस्यमहारा ऋक्षवमशुरहनीमहायक्ष सेनापतिनीरूपमाणि॥ यस्त्रान
क्षनिपतिपासयंति॥ इन्द्रियंयदवीर्यमपसव्यंसाकस्त्रनास्त्यति॥ साकानुगार्थंसाकमनुविवस्त्रति॥ तद्यथा

ॐ दसाम॥ सूर्य्यवसव॰ यज्ञायज्ञियस्य राज्ञॐसानस्पदन॥ कामधरूक्ष्मनिकथकवर्त्तिमनिमानिच॥
पक्षमदउपयक्कक्मासागिरिहेमवता॥ यूस्त्रीवदितकाविदःगोपायक्षश्राउवकानसराजाजिनवर्क्ष
पक्षालगाक्षुस्मूस्वादिर्पयक्ष॥ पक्षलिंगनःचितसनेवगधर्वक्रिकलीचनिकएष्ठका॥ दिर्पसकिंस्यमात
सिंत्रनयक्षामहायक्षासेनायापतिनायका॥ यद्धिनत्रायूमतावर्क्षुवेत्रायसत्रिना॥ दवास्त्रमधिसंग
मननूरुवतामदृष्टिका॥ वेणुमतास्यमहाराजस्यधमजुतसोयषीवेसमलमहाराजाश्रासोचपति॥ अ
यंमयक्षोविरुव्यतिःस्यैमयक्षानमूरुति॥ ॐमवेणुवनस्यमहाराजधर्म्मजुतस॥ रुयनयामहामा
यूर्क्षविद्यालाक्षामनसपतिवासस्यस्तवस्त्रानीवकूवंरुमुक्तिंपतितोनपतिगरुपतिपासनंमनस्य

स्त्रायनंदक्षुपतिहासंसक्रूपतिहासंविषदूषनंविषक्षासनंसीमावंधटसनीवंधरूकूर्वंतुशिवतुवर्ष
सनंपश्चतुरदांसनं॥ पतिनायतुकसिंकसहस्रुनविगहविवादारूपतिपासत्यतुमनूष्यगंधहातसमनूष्य
गंधहात॥ देवगंधहा गो.नागगंधहा गो.यक्षगंधहा गो.मलगंधहा गो.गंधवगंधहा गो.किंनरगंधहा गो.मरुद्गंधहात
यक्षगंधहात.राक्षसगंधहात.पेतगंधहात.पिसाचगंधहात.हूतगंधहात॥ कूष्मानूगंधहात.पूतनंहात्रःस्कंधगंधहा तः
उन्मादगंधहात.ज्वरागंधहात.अपस्मारगंधहा गो.उरुकावेगंधहात.नक्षतगंधहात.रुयनगंधहा गो.ममसत्रीकूर्वंतु
उंजंघहासिनी गो.गंधहासिनीत.सीसाहासिनित.सुधिहासिनि गो.वसाहासिनि गो.मदाहासिनि गात्रं.मज्जाहासी
निता.अस्रुहासिनि.शिक्षिहासिनि.वस्त्रहासिनिनि.मांसाहासिनिता.गंधहासिनि गो.सूयाहासिनि गो.पूयहासिनि

कुसाहासिनिका.सस्वादासिनिका.अरुच्याहासिनिका.यूष्याहासिनिका.विस्फोटासिनिका.मूदाहासिनिका.क्षिप्ता
सिनिका.क्षुद्रमाहासिनिका.सिंहानकाहासिनिका.वातासिनिका.विसिक्षाहासिनिका.अरुच्याहासिनिका.ह्यदया
सिका॥लक्षाकृवंतुनमस्तपसिवासत्यसवसत्यानांचकर्म्मिकासाद्यकिंतसमाकाहवनाकाहवनीकाउ
न्मर्दनाताहूताश्चताताका॥विस्फोटकंपिडकादुर्जुकंदूष्यंदितदूसाश्चयादूष्यक्षेत्रंदूसिवीत्रदूसयिताबधू॥ १००
कातउत्सादनउद्वासनाउत्क्लासकाकंअरुचस्माकाविनासनालक्षकंतु॥राजरुयाचोरुयाअरोनिरुयातकंउ
दकरुयातकंपसचकरुयातकंदूष्यिक्षरुयातकं॥अरुनिरुषातकंआकासमरणुरुयातकं॥वसलीकम्यरुया
नोषनिकरुयातंचसुमरुयातं॥अमितरुयातंवंधकरुयातं॥पस्यधिकंपस्यमिनरुयातंमसनरुयातंसवीरुयाकं

लक्षाकृवंतुदद्रुकंतुरुष्किटिभरुगदसाकुष्ठंगतुपिटकयामाचेत्यरोगरुयातं॥अपनयकुसिरोग्व
मर्छवरुद्धकमरोचकंअक्षिरोगानासारोगंमूखरोगंकथरोगंहृदोगंवातरुग्रहंकनतूलंदंतनूलंहृदयतू
लंपार्श्वतूलंपृथतूलंमूदतनूलंगतुगूलंवस्तिगूलंगुदतूलंयानितूलंपजनतूलंमूत्रतूलंशेषालतूलं
हृल्लासतूलंयादसतूलंमक्षपुत्यङ्गतूलंठसमपनयतु॥अकाह्निकंद्याह्निकंत्याह्निकंचतुथकंपञ्चाह्निकंम
र्द्धमासिकंमासिकंद्वेवस्तिकंमोहरुष्किकंनित्यतूलंविषमतूलंरुतूलंमानूषतूलंवातकंपेतकंश्लेष
मकंसंनिपातिकंदूर्जुकंसर्वतूलंसप्ताहजीर्णंसवव्याधिसर्वगंसवरोसवविषंसर्वपापंसवदुःख
सवरुग्यञ्चसमासयनाशयतुमनसपसिवास्यसवसत्यानाञ्चस्याहा॥द्वादसमाश्रयनदमहाग्रिमाश्रो

यद्धि वो ऽग्निस्त्वोमातुथा कूक्षिगतास्त्रिताऽजायमानास्त्रिताजायताग्निस्त्वा पुनः कृण्मो ऽदक्षिणा
यैतास्थ यत्र यथा॥ सम्वा विसम्वा पसम्वा डासम्वा डासिनी हसिक्का डसिर्विंगसाकासिक्तासिक्म्यू
ङीवाकाकंकसल्मादसिवंसीङ्क्ष्य कछादस्तमदाधिसास्थाऽऽद्धिमतायूतिमकाव नवकायसम
स्त्वा॥ देवसुतमधिगसाममनूरुवतिमहयिका॥ नायनयामहामायूर्य्यीविद्यासाङ्क्षाममसपसि १०१
वासस्यसवस्त्वानींवस्त्वाकूवंकुटिंपसितानंपसिगहंयसियासनंभतिंस्वस्त्वयनदर्भपुः
सितासंस्तमृपसिक्तसंविषदूखनंसीमावधवसन्विषङ्कूवंकुटिंवतुवर्षसेतपूष्णेऽसतदीसनं॥
ङ्कमानिवातमनयदानिमनसिकृत्वानि॥ नयक्ष॥ ससैषरक्षसमसेमिरेमूरेमदंगिमरुमरुमशि

निक्का हसहसहसहसहसहसहसहसहसहस॥ १०॥ सतसत्॥ ४॥ मतिमतिमतिमति॥ ४॥ सिद्धिसिद्धी
सिद्धिसिद्धी॥ ४॥ स्वस्तिस्वस्तिस्वस्तिस्वस्ति॥ ४॥ ममसपसिवासस्यसवस्त्वानींवस्त्वाहा॥ ॐ॥ मानंद
महायिसास्वामीऽभतिनसंसिका॥ मनूस्थाऽभंविकंठकायाग्निर्वाधस्त्वामातु॥ कूक्षिगतास्त्रिताऽजायमानौ
सक्षित्राऽयिसंसिकायूनकृण्मोकनका॥ नयथा॥ मदामदनानामद्रोकंडाऽपमदायनिऽजाहासिनिऽरसनि
गडनिवर्तिन॥ ॐ॥ स्थौताऽरुमहयिसार्वाऽऽद्धिमस्थायूतिमस्थावकूवंकुटायसस्त्विच्यादवास्तमयिसैगमम
मनूरुवतिमहयिका॥ नायनयामहामयूर्य्यीविद्यासाङ्क्षाममसपसिवासस्यसवस्त्वानींवस्त्वाकूवंकुटं
ङिंपसितानंपसिगहंपसियासनंभतिंस्वस्त्वयनंदर्भपुंसितासंस्तमृपसितासंविषदूषनंविषनासनं

स्तिनावैषवतनिवऋक्कूवंतुजिवतुर्वषतनैपग्धतुसदासतैं॥तथा॥हुसैखसखूसैमसमूसमदनिसं
तिमलुमलुनिकाहुतहुलहुलहुलहुलहुलहुलहुलहुलहुलहुल॥१०॥लललल॥४॥मतिमतिमतिमति
॥४॥सिद्धिसिद्धिसिद्धिसिद्धि॥४॥स्वस्तिस्वस्तिस्वस्तिस्वस्ति॥४॥ममसपत्नीवास्यसर्वसत्वानींवशमाना॥
हुमापूनस्तानदफनक्षपिसाध्यामीसृग्मालिनहोंजिकामनूच्चा ह्रौं हि०कायाहि वौषिसत्वामाकुरुकुरुस्वा १०२
सृष्टिजायमानीसृष्टिनोजागृतिपिसृष्टिनोतापूनकनमाशुद्धयाश्रुमदिकासृष्टिनिकाविपिशमविम्ब
पूर्तूलदिकाश्रुनीसृष्टिनिकामितकासिकाजविसृष्टिकाविनिहुन्धतासफमक्षपिसाध्यामहिमी
क्षायूनिमीक्षावनुवनायसत्विद्य॥देवस्तमपिसंगममनूत्वत्रिमहार्द्धिकाःनायनयामक्षमाय

र्यांविद्यासाक्षममसपत्नीवास्यसर्वसत्वानींवशमाकुरुकुरुंपशिनांपशिगृहंपशिपाशनींशा
खिंस्वस्त्ययनंदनुपशिक्षासंशमंपशिक्षासंविषदूषनंविषनोंसिमावधयसत्वावचऋक्कूवंतुजुः
जीवंतुवर्षतनैपग्धतुसदासतैं॥तथा॥हुसैखसखूसैमसमूसमदनिमलुमलुनिकाहु
तहुलहुलहुलहुलहुलहुलहुलहुलहुलहुल॥१०॥लललल॥४॥मतिमतिमतिमति॥४॥सिद्धिसिद्धिसिद्धि
सिद्धि॥४॥स्वस्तिस्वस्तिस्वस्तिस्वस्ति॥४॥ममसपत्नीवास्यसर्वसत्वानींवशमाना॥अरक्षिपूनस्तानदप्र
ऋमक्षपिसाध्यामीसृग्मालिनहोंजिकामनूच्चा ह्रौं विहृ०कायाहि वौषिसत्वामाकुरुकुरुगीसृष्टिनो
जायमानीसृष्टिनोजागृतिपिसृष्टिनापूनकनमाशुद्धयाश्रु॥तथा॥कुरुकुरुनिकुरुकुरुनेदाविपुरुषाकपिसाधेनि॥

ह्रूंह्रूंनाथंवमकलासाक्षस्थाऊर्द्धमंस्थायूंमिंस्थावनवक्षपसम्बिंस्वाहादेवासंसमधिसंगममनूरुवंमिंहर्द्धिकांकायनयामहामायूंथिंविद्यासाक्षंमनमसपंसिद्धवासंस्यसवंसखानींवंसक्षींकूंवंकुंकुंकिंपंसिगांनंपंसिगंहंपंसिद्धवासनंठंमंतिंस्वंस्वायनंदंकुंपंसिद्धासंसंकंपंसिद्धासनंविंषंदूंषनांसनंसिंमांवंधंधंसंतीवंधंकूंवंकुंजिंवंकुंवंषंसंतंपूंजंधंकुंसंसंदींनांनंयंथांहंसंषंसंषूंसंमंसं

लक्षिंनांजांगंथिंसंक्षिंनांपूंनंवंकंमांऽरंक्षांनंयंथांमंहांसंसिंमांकूंस्यंक्षंकंसंनिंकंस्वांजांसंमिंनांसांहिंनांक्षिंकं
वंलांचंलिंनांऽकंमांमंकंमंहांलांक्षंस्थांमींसंठंमंसिंनंहांजिंकांमंनूंष्यींनांमंविंकंठंकांकंसंत्रिंमींपूंसूंषंदांसिंकांऽरं
स्तंत्रिंकांकूंसांनिंसंवंत्रंमूंष्यांगंमंसंऋंकंमांपंठंवांगांकंठंनिंगंदांपंयंतिंमंनूंष्यींनांऽजांजांकंसंतिंमंहांकंत्यां
नंगांसांमंक्षिंकांसूंष्यंनांसंयंतिंचंमांनूंषींम्यंजांऽकंथंनांऽरंकंमंहांलांक्षंस्थांसंऽर्द्धमंस्थांयूंमिंस्थावनवंक्षं
यंसंम्बिंस्वांयांदेंवांसंसंमधिंसंगंममनूंरुवंमिंहर्द्धिंकांकायनयांमहांमायूंथिंविंद्यांसांक्षंमनमसपंसिंद्धवांस
स्यंसवंसखानींवंसक्षींकूंवंकुंकुंकिंपंसिगांनंपंसिगंहंपंसिद्धवांसनंठंमंतिंस्वंस्वायनंदंकुंपंसिद्धांसंसंकंपंसि
द्धांसनंविंषंदूंषनांसनंसिंमांवंधंधंसंतीवंधंकूंवंकुंजिंवंकुंवंषंसंतंपूंजंधंकुंसंसंदींनांनंयंथांहंसंषंसंषूंसंमंसं

मदंत्रिनेत्रमित्रमर्कनिकाहलहलहलहलहलहलहलहलहलहलहलहल॥१०॥सलसलसल॥६॥मतिमतिमति
मतिमतिसिद्धिसिद्धिसिद्धिसिद्धिसिद्धिसिद्धि॥६॥स्वस्विस्वस्विस्वस्विस्वस्वि॥६॥मनसपसिवासस्यसर्वसत्त्वानांवशमा॥
दसमानदसहस्राक्षस्यायाहिवोषितस्वामानुकूलिनीलक्षिनीजायमानालक्षिनीजानायिलक्षित्र॥नायून
कमानदसनयआ॥हासिनिसाक्षसिनदासाक्षसियिनासाक्षसिसैविनिसाक्षसिकासिकासाक्षसिदवसिनासा
क्षसिकूतासाक्षसिकूंदवल्लीसाक्षसिसंविकासाक्षसिकलसदसिसाक्षसिकल्पवादसमहासाक्षस्यास्मर्द्धिनस्या
वर्नुवकासयमस्विद्या॥देवासरसमपिसंगममनुरुवतिमहर्षिकागायनयामहामायूकीक्रियासाक्षमम
सवपसिवासस्यसवसत्त्वानांवसंक्षींकूर्वंतुगर्ह्यिंपसिनानपसिगर्हंपसिपासनंसाक्षिस्वस्ययनंदह्यपसिहासं

स्विदूषनंविषनासिसीमावंधयसगावधकूर्वंतुजीवनुवर्षसंयग्धसत्तदीसतोनयथा॥हसवसवसमसमि
समूसोमदंतिमलंतिमलमनिंत्रिकाहलहलहलहलहलहलहलहलहलहलहलहल॥१०॥सलसलसल॥६॥मतिमति
मतिमतिमतिसिद्धिसिद्धिसिद्धिसिद्धिसिद्धिसिद्धि॥६॥स्वस्विस्वस्विस्वस्विस्वस्वि॥६॥मनसपसिवासस्यसर्वसत्त्वानांवश
स्यहा॥दसहस्रोंजानदसहस्राक्षस्यायाहिवोषितस्वामानुकूलिनीलक्षिनीजायमानालक्षिनीजानायिल
क्षितानायूनकमानदसनयआ॥अनाथिकासाक्षसिसमूहासाक्षसिसोदासाक्षसियानहासिनिनासाक्ष
सीविषावनासाक्षसिवनूषसानासाक्षसिसवसवसानासाक्षसिअसिवसानासाक्षसिहसवसाना
मसाक्षसिवकवसानासाक्षसिवकवाजनासाक्षसिविदायनासाक्षसिकस्यहादसमहासाक्ष

कायनानीस्वाहा सम्यग्दर्शनानीस्वाहा सम्यक्चरित्रनानीस्वाहा वज्रहस्तायस्वाहा वज्रदंष्ट्रायस्वाहा वज्रनखायस्वाहा
वज्रसानायस्वाहा सर्वमन्त्रयस्वाहा सर्वविद्यायुधायस्वाहा चलुनायस्वाहा गमायस्वाहा उपदायस्वाहा वैश्रवनायक्षाधी
पतयस्वाहा धनदायक्षाधिपतयस्वाहा विरूढकायक्षाधिपतयस्वाहा विरूपाक्षनागाधी
पतयस्वाहा दवनीस्वाहा धनानीस्वाहा सरसानास्वाहा मरूतानीस्वाहा सूरूतानीस्वाहा गधवानीस्वाहा महास
मनास्वाहा किनसानास्वाहा यक्षानीस्वाहा राक्षसानीस्वाहा पतानीस्वाहा पिसाचानास्वाहा कूष्मा
ण्डनीस्वाहा पूटनानीस्वाहा स्कंदनीस्वाहा उन्मादानीस्वाहा छयानीस्वाहा अपसमारानीस्वाहा डाकनीका
नीस्वाहा वडवामुखीयास्वाहा सूदानीस्वाहा सभगानीस्वागतानीस्वाहा सर्वसिद्धेभ्यस्वाहा सिद्धवना

गुरुभ्यः यानिभ्यः यजनगुरुभ्यः ऊंघालगुरुभ्यः हस्तसर्वेभ्यः पादगुरुभ्यः अरुंधत्यरुंधगुरुभ्यः हुतासर्वगणेभ्यः विघ्नासर्वेभ्य
यःस्वस्तिरस्तुनमस्तवस्त्वानाकरुस्वस्तिसोमायस्वस्तिदेवायस्वस्तिमरुद्भ्यःस्वस्तिसर्वमनु
ष्यभ्यःसर्ववृक्षादित्यःनमोनमःकुवायनमःकुवेरायनमोनमःकुरुकायनमोनमःकुरुविंदा
यनमोनमःकुरुविंदकायनमोनमःकुलत्थकायनमोनमःसर्षपेभ्यःयवाकरेभ्यःवाहितवायाःयमीरुषाःनमस्तक्षभ्य १०५
स्तवस्त्वानाकरंशाकुर्वंतु॥स्वस्तिमातुःस्वस्तिपितुःस्वस्तिगर्भस्यस्वस्तिक्षियदानीं॥स्वस्तिवक्ष्यदानीं
स्वस्तिवक्ष्यदानींस्वस्तिक्रियमाणायैषीनानींस्वस्यमुनमस्तवस्त्वानींकरत्यात्॥उरुक्रमायनदनागसा
ह्वानामानिनागपत्नीवृक्षाःरोगवानागराजा॥वक्रनागराजा॥महावक्रनागराजा॥कुंदानागराजा॥समुद्रा

नागराजासमुद्रपुत्रीनागराजाहरितानागराजा॥रोमणतीपुत्रीनागराजाम्बुसानागराजानदीनागराज
उपसानागराजानलोमनागराजाउपनसानागराजासुदर्शनीनागराजावासुकिनागराजानप्पंकीनागरा
जाअस्तूलमनागराजावस्तूलमनागराजापांडुरकीनागराजाषडंगुलीनागराजाहास्तम्भनागराजाश्री
मानागराजाश्रीकंथनागराजाश्रीवर्द्धनानागराजाश्रीरुंदानागराजाअरुणनागराजागवलीनाग
राजाअरुंधिवलानागराजासप्तशीर्षनागराजाअरुंधकीनागराजासुवाहुनागराजासुरुचाहुनागराजा
सुभमुखनागराजासुव्यंजनीनागराजावदपत्नीनागराजाहृदकानीनागराजानदुनानागराजागर्ज
नानागराजाम्बियादनीनागराजास्थूलनागराजावर्षनागराजाविषनागराजाम्बिमसाना

गसाग्राअरलकसिष्पनागसाग्रावसकगीर्षनागसाग्राअश्वगीर्षनागसाग्रागवयगार्षनागसाग्रा
मगसिषानागसाग्राहस्तिगीषानागसाग्रानसमिहानागसाग्राअदेवसिकानागसाग्राअनादसानागसाग्रा
म्विकानागसाग्राम्विनसनानागसाग्रानमूम्विनागसाग्रामूम्विसिद्धानागसाग्रासावस्मनागसाग्रा
सापवनागसाग्रामिसिनागसाग्रासिसिकानागसाग्रासम्बूलनागसाग्राकिमिनागसाग्राअनकानागसा ११०
ग्राकटकानागसाग्राहस्तिकर्णनागसाग्रापालुकानागसाग्रायिदसानागसाग्राप्रसपकानागसाग्रा
अरालसिथिनागसाग्रासेषपासनागसाग्राहस्तिनागसाग्रावनसाकूनागसाग्राविस्टकानागसाग्रास्वे
सपाक्षनागसाग्रावेसमनानागसाग्रासकटमूरवानागसाग्रापाकसकानागसाग्राहमेनमानागसाग्रापाकसका

नागसाग्रासकूतनागसाग्रावल्कलनागसाग्राविदुनागसाग्राउपविदुनागसाग्राअरिमिनागसाग्राकुलि
कानागसाग्रामिकरकानागसाग्राकोनानागसाग्राउपवासानागसाग्राविश्वनागसाग्राकुकुरमेनम
नागसाग्रामानूषानागसाग्राअमानूषानागसाग्रामूसमानूषानागसाग्रापूवमानूषानागसाग्राउतस्मा
नूषानागसाग्रामानंगिनागसाग्रामनुकानागसाग्रादनुसानागसाग्राउतसकानागसाग्राउकुसानामसा
जाग्रासूलूकानागसाग्राउरुसमानागसाग्राव्रसानागसाग्रावसिनागसाग्राअस्वासानागसाग्रामस्वासानागसाग्रा
मसम्बिनागसाग्राकपिसानागसाग्राहोलवसानागसाग्राउल्यसानागसाग्राककोटकानागसाग्रानखकी
नागसाग्रावज्रकानागसाग्रामाश्रकानागसाग्रावृश्चिकानागसाग्राकम्बलसम्बलनागसाग्रानी॥

ऽस्यदनागराजाऽऽसानानागराजाऽमहासिदर्शनानागराजाकपिलिकानागराजापाशिकोनागराजा
तूलवर्तमूखेनागराजाऽऽदत्तमूखेनागराजागवेलानागराजासिंहसेनागराजादविधानागराजा
वसदेवीनागराजानासापनीनागराजाकन्कत्वम्बसानागराजाविरिंचिनीनागराजालक्षस्यनागरा
जाठोवलवाहनागराजागंगमनागराजासिंदूनागराजासिंहानागराजावक्षकोनागराजाऽम्बदसाना ११२
गराजामंगल्यानागराजाऽनंतमुखकानागराजासूर्यविथकोनागराजाश्रेनावनीनागराजाधस्र
स्विवनीनागराजाऽस्वकमित्रीनागराजाऽकनिधसेनागराजारुद्रानागराजासुरुद्रानागराजावस
रुद्रानागराजाऽनिरुद्धानागराजामणिकष्टेनागराजासकनासिनागराजावस्त्रीनागराजारुद्र

नागराजाऽदुर्दुरुंनागराजाऽयदुदुरुहिनागराजाऽदुंदुरुहिनागराजाऽमलिकानागराजाऽछोकुछूको
नागराजानोऽछोकुछूकानागराजानेऽवृषभुकसेनागराजानोऽकमिकुभुनागराजानोऽउछूसा
नागराजानो॥ १११ ॥ऽकेयतानागराजानोऽयस्मिंश्चथिविमंडुसेनकासंगजयंतिऽकासनकासेवी
घडवथाकर्यलिऽकासेनस्यनिधादयंति॥वृषकसिसामृद्धिनस्मिंशायदा॥ऽमितसेनंगनादिघायूघाऽक
स्यलायिनोऽविमूक्षगसूतरुयातऽअग्निवासूकरुयातराजकरुयातऽवसनिकंपरुयातऽवसधासामत्त
मालत्वविमाननंवाग्निनेनाद्विघायूखमरुयामधामरुधिकाऽमहाकालमहानूरुवाऽमहापरिवासा
ऽरसिवसपरुंजकाऽस्द्धिनगाकुनिमगावनमयस्त्विना॥ऽवासरमधिसंगमनूरुवानिमरुधिका

ह्रूंक्ष्यंक्षानागराजा.सपूजाहंयोगोंसहाहस्त्रांमाक्षांसत्यनाथतयःसदूतासपत्न्याश्चसपत्नयाःसपाषदोनेत्यन
त्यानन्दमहामायूरिविद्याराज्ञीकनकमुनिनासत्यक्ष्वींकूंवुंजिवज्रवषंतपस्यनुसत्सदासतांस्वः
स्फिरुवनुमनसर्वसत्वानांस्यात्ताऽस्थिरुनृसिंहस्यमनतस्यांपमरूस्यगंऊंक्लिष्टनांनिषनत्यर्थनस्य
आगतांआगतस्यानागत्यस्फिसारुजरुयातांयोसरुयानकांऽदकरुयातांवंधनरुयातांपत्यधिकरुयातांपत्य
मित्रुयातांऽलासरुयातांपसवकरुयानकांदूरिभरुयातांअंकासस्त्यरुयातांदुस्वप्नांकंपरुयातांवद्युम
नरुयातांस्फिदवरुयातांनागरुयातांअरुंसरुयातांमसूरुयांगांगसूरुयांगांगधवरुयांगांकिनसरुया
गांमसिनसरुयात्रांवक्षरुयांगांसाक्षसरुयांतांपिसावरुयांगांपंरुयांगांजुरुयांगांकूलांसुरुयांगांपू

कूंकूंक्रंदनसक्रंहूंनरुधिरावाद्यनूमादिनाचांगलयथांहिंतिमिंतिकूंतिमांतिंतुंतिंशांतादंतिसिंसक
लिकनसिंथगसिंवगसिंकाकूंनकांकनावलिंधरेंसवसोवसवसवसवसवसवसंदनसिंहिनिखं
कांऽहूंयंवानंदमहामायूरिविद्याराज्ञीकनकमुनिनासत्यक्ष्वींकूंवुंलखिनावाद्यनूमादिनाचांगलसे
वतसरुंगनतेरुनस्यविरुंजिवर्यंयविजयतेंओंसंजविसंजांक्रांजांमसिमनिमांसिंसिंसिंनमनुसिंसि
नुंजसंजसंजसंजसंजसंजसंऽरुंदवंदिंसिंखिलांतांस्यंवानंदमहामायूरिविद्याराज्ञीकांस्यंवंसमं
क्षींवज्रनरुधिरावाद्यनूमादिनाचांगलयथांअरुंतेंकंगुरुंमनुरुंखंठंसोंजंम्बूंजंम्बूंदिंजंम्बूंवनिम
रुमादिनिकांऽमरुंतेंसिंद्धांहरुंहरुंहरुंहरुंस॥४॥यंठंयंठंयंठंयंठं॥४॥यंठंयंसिंसिंस्वांहां॥ऽ

ॐ नमो भगवते अरिष्टनेमिनाथतीर्थंकराय सर्वविघ्नविनाशाय सर्वशान्तिकराय सर्वपापक्षयकराय सर्वरोगापमृत्युविनाशाय सर्वभयोपसर्गविनाशाय सर्वदुष्टग्रहविनाशाय सर्वदुष्टशत्रुसैन्यविनाशाय सर्वजनवशीकरणाय सर्वजनमनोहरणाय सर्वजनसंजीवनाय सर्वजनसुखदाय सर्वजनानन्दकराय सर्वजनसम्मोहनाय सर्वजनजृम्भणाय सर्वजनरञ्जनाय सर्वजनक्षोभणाय सर्वस्त्रीपुरुषाकर्षणाय सर्वजनवशंकराय सर्वमुखरसनस्तम्भनाय सर्वशत्रुमुखबन्धनाय सर्वशत्रुविद्राविणाय सर्वशत्रुविद्वेषणाय सर्वशत्रुविमर्दनाय सर्वशत्रुविध्वंसनाय सर्वशत्रुविनाशनाय सर्वशत्रुभयंकराय सर्वशत्रुजनकाय सर्वशत्रुजनकाय सर्वशत्रुजनका

हसरनसरसिसिरदादादादा॥ज॥दादादादादा॥ज॥वावावावावा॥ज॥पापापापापा॥ज॥हसहसहसहसहस
ज॥सिद्धसिद्धसिद्धसिद्धसिद्धसिद्धसिद्धि॥ज॥सवसत्वानांवशमानयस्वाहा॥स्वस्तिपक्षकालयमदूतान्कालरात्रिकालया
त्तनमस्कृतदन्तुनावज्रदन्तुनाहेददन्तुनामक्षिदन्तुदेवदन्तुनानागदन्तुनाअसुरदन्तुनामनुष्यदन्तु
नागरुन्तुनागंधर्वदन्तुनाकिन्नरदन्तुनामहोरगदन्तुनायक्षदन्तुनाराक्षसदन्तुनापिशाचदन्तुनाभूतदन्तु
नाकूष्मान्डदन्तुनापूतनदन्तुनाकटपूतनदन्तुनाकदंदन्तुदाडमादन्तुनाश्वयादन्तुनाअपस्मारदन्तु
नाउन्मादकदन्तुनावेतालदन्तुनाशवदन्तुनाशोषदन्तुनाअस्थिदन्तुनाडदकदन्तुनासर्वदन्तुक
दन्तुनास्वस्तिरस्तुतेस्वाहेहि श्रीसर्वसिद्धानांवशमिवतुवषट्सर्वपरविद्याछेदनकरीमहाप्रत्यं ११६ट

साहीनामानिनयथागंगनदिसाहीसिंधनदिसाहीवक्षूनदिसाहीसीतानदिसाहीसरयूनदिसाहीअजी
रवतिनदिसाहीयमूनानदिसाहीकुहानदिसाहीविपाशानदिसाहीशु
तावतिनदिसाहीचंद्रभागनदिसाहीसरस्वतिनदिसाहीकौशिनदिसाहीपयोष्णीनदिसाहीदेवी न
साहीतामपनावतिसाहीमधुमतिनसाहीविदेवतिनदिसाहीकृष्णमतिसाहीपूर्णासिनिनदीसाहीगंभतिन
दीसाहीचर्मवतिनदिसाहीनर्मदानदिसाहीतोमितानदिसाहीविश्वामित्रानदिसाहीअमृतानदिसाहीयावा
सानदिसाहीलोहासुनदिसाहीपरुष्णिकानदिसाहीनद्यादानदिसाहीविनसानदिसाहीविनसानदिसाहीने
रंजनानदिसाहीमहानदिसाहीनथस्यानदिसाहीकौशिगायाच्यावनायास्मिपृथिविमनुष्यंवैतिया

ना स्तुसर्वाभूतदिषूयदेवानाम्अस्तूसानसूगसूशगधर्वाकिनरामहासम्मयक्षासासाधताविसाधकूना
कूक्लाम्लुपूतनाकतपूतना॥स्कदाऽमाम्लु क्ष्याश्रपस्तमासाजाक्लासका॥डाजाक्लासागक्लाक्लासासूधिक्लासावसाक्ला
सामीसाक्लासामदाक्लसामजाक्लासाजाक्लाक्लासाग्रिधिनाक्लासावस्याक्लासामास्याक्लासाग्रामक्लासाक्लाक्लासा॥वूधाक्ला
सासत्यक्लासा॥अङ्क्ष्याक्लासापूजाक्लासाविकूक्लासामूना॥खदाक्लासाक्लूस्वाक्लासासिक्लानकाक्लासाऽकिक्ला
क्लासावामाक्लासा॥अस्तूस्याक्लासास्यदनिकाक्लासानानासूयाविसूयावक्लसूयाअनसूयाभेकामसूयाविधिनसूया
भेवासिकापनिवर्तनि॥कपनयामक्लामायूयीविधासाक्लास्वाकरिक्लासक्षीकूर्वतुशिवंतु वर्धसेनपम्मीतु
सलदासर्ंडमूक्लक्षमानदपक्लनसाक्लनामानि॥कथासूत्यसूपवनसाजाक्लिनवामपवनसा॥नाथ

मानपर्वतसाजासक्लभूक्ला॥पवनसाजापातसकपवनसाजासूवनपाक्षपवनसाजाधूनिधसाधवनसाजा
निमिधसपवनसाजा॥चक्रवाकपवनसाजामक्लावकवाकपवनसाजा॥कुन्दसोसपवनसोजाकवक्लास
पपवनसाजा॥श्यामनपवनसाजासूदसनपर्वतसाजाविधूसपवनसोजासनाकसपसवनसाजाकिम्मिस
पवनसाजामनिकूतपवनसाजावैमचितपवनसोजावजाक्षपवनसाजाअस्तसपाक्षासपवनसाजा॥अ
नूमचितपवनसाजाविधूस्वरूपवनसाजाअस्वक्षपवनसाजाकुन्दसोसपवनसाजासूर्यकानपर्वतसाजाः
क्षिदूपर्वतसाजासिक्षपर्वतसाजा॥चित्रकूटपर्वतसाजाकवतुसेसपर्वतसाजामसपपर्वतसाजासूव
र्णशृंगपर्वतसाजा॥पसिजानपर्वतसाजासूवाहपर्वतसाजामनिमैनपर्वतसाजासूसूनपर्वतसाजाव

क्ष उ नु पर्वत राजा वदगच्छ पर्वत राजा रमक नय पर्वत राजा मा स्य चित्र पर्वत राजा ख भ्र य पर्वत राजा या
य न य पर्वत राजा ऽर्ज न य पर्वत राजा मृ ज न य पर्वत राजा सू ह य पर्वत्र राजा दर्द र य पर्वत राजा के सा म य पर्वत रा
जा म क न्दु य पर्वत राजा स्त ट य पर्वत राजा क र्ज र य पर्वत राजा ऽ या सि न्द्र य पर्वत राजा ख ग सि सि य पर्वत
राजा वदन मा स य पर्वत राजा व स न्त मृ द्ध य पर्वत राजा को क नाद य पर्वत राजा ऽ म स नाद य पर्वत राजा ऽ ह्य
के वा य वा स्मि पृथि वि मनु स य पर्वत राजा तत य देवा ना म ऽ स्तु सा म सू ता गा सू ता गं ध वा कि न सा म
हा स गा य क्षा सा क्षा स पा शि सा वा ह्ता कू स्ता न्धु पू तना क दा ऽ मा न्धु क्षा या ऽ य स मा ता ऽ क्ष स का
सि मि वि द्या ध र सा ऽ ना न स य सि वा सा न मे वा सि वा सि का य नि व सं नि ध ने प न या म ग्रा मा यू यी वि द्या सा ॥

रू स्वा नि हि ऽ ऽ रा क्षां कू व न्तु जि व न्तु व र्ष सं न प न्थ नु स दा सं न ॥ स व या ना प न य नु क्ष्या न ष सं दृ शं नृ ॥
ऽ क स्था नं प नि के ध य न्तु ऽ थ ष त दृ ध नै ऽ र न र्थ प नि वो ध य न्तु स्वा नि क्षा ॥ स र्व स त्वो ना च नो स्व स्ति म
स्व दि ना हि न ॥ स्व स्ति स र्व म क्षा रा नं स र्व वृ द्धि स न्तु व स्वा हा ॥ ऊ रू क्ष्व मा न्द न क्ष त्र ना मा नि ॥ य गा ह्ना
वि र ज नि य था रू नि का रा द्धि नि वे व न्त गा ह सा दा यू न व स ॥ यू क्षा मं ग र स्तं प ना मृ ष्वा क्ष्व नि स क मि ॥
ॐ ख्वा ना स क न क्ष त्रा यू र्व द्वा री का हि ना ॥ य यू वा दि सं स क्ष नि प सि या न य नि ॥ ऊ ह्य प न या म ग्रा मा यू वि द्या
रा ह्ना स्वा नि हि क्षा ॥ स व स त्वो ना च य र क्षा कू व न्तु जि व न्तु व र्ष स तं प थ नु स दा सं न ॥ म या वा सि न म थ नि क्षा
रू ऽ ह्मो हि न थे व व ॥ ह स्ता वि ना स्वा नि धि सा वा क्ष्व न्तु स क मि ॥ ॐ ख्वा ना स क न क्षा दा क्षि न द्वा सि का हि ना ॥

यदक्षिनादिसंरक्षतियसिषासयति॥ कथनयामहामायूरीविद्यासाह्वास्वाहरक्षासर्वसत्त्वानांरक्षांकुर्वंतु
वर्षसंतंयन्मनुस्मरसदासतं॥ इतूसाक्षमहाकल्पाकथामूलाग्नेयेस्वपूर्वोत्तरसाखाटंरक्षिक्षिनक्षत्रवतांकृत्य
नाक्षत्रकनक्षत्रापश्चिमहासिकास्थिताय॥ यपश्चिमादिसंरक्षतियसिषासयति॥ कथनयामहामायूरीविद्यासा
ह्वास्वाहरक्षासर्वसत्त्वानांरक्षांकुर्वंतुगिर्वंतुवर्षसंतंयन्मनुस्मरसदासतं॥ धनिष्ठानक्षत्रकृतिषाविषाखेव ११२
उत्तरादपदेनथा॥ सर्वत्रिवासनिवेवहरक्षनिरुक्तिसकर्मि॥ इत्थंनाक्षत्रकनक्षत्रउत्तरहासिकास्थिताय
उत्तरहासिकास्थिताय॥ यउत्तरादिसंरक्षतियसिषासयति॥ कथनयामहामायूरीविद्यासाह्वास्वाहरक्ष
सर्वसत्त्वानांवयरक्षांकुर्वंतुगिर्वंतुवर्षसंतंयन्मनुस्मरसदासतं॥ इदृष्टद्रुक्षमानदग्धदानींमानिमंयत्र

वानामनक्षर्षिमाविचिनामनक्षर्षिमार्कंडेयानामनक्षर्षिनिष्प्रभिगामनामनक्षर्षिवसिष्ठनामनक्षर्षिवामी
कोनामनक्षर्षिकाश्यपानामनक्षर्षिवृद्धकाश्यपानामनक्षर्षिरेभनीनामनक्षर्षिरेभीसूत्यनामनक्षर्षिअंगीरसानामा
मनक्षर्षिरेभीनामनक्षर्षिअंगीरजानामनक्षर्षिक्षमयानामनक्षर्षिपूरुस्थानामनक्षर्षिरेभसिसाक्षर्षिप्य
मदग्निनामनक्षर्षिरेभसंपायनानामनक्षर्षिकक्षुरेभसंपायनीनामनक्षर्षिहारिणगानामनक्षर्षिसनगिसामनक्षर्व १२०
उरुक्षयनामनक्षर्षिसमूगकानामनक्षर्षिसाकिवादिनामनक्षर्षिरेभिनामनक्षर्षिसरेभिनामनक्षर्षिा
गूरूनामनक्षर्षिमरुतेनामनक्षर्षिमरुनानामनक्षर्षिपतंकानामनक्षर्षिअरुवसायनानामनक्षर्षिहि
मवानामनक्षर्षिसाहिनाक्षानामनक्षर्षिरेभसंपायनानामनक्षर्षिदूर्वासनामनक्षर्षिपरुनामनक्षर्षिसरुनामनक्षर

क्षर्षिदक्षत्यतिनामनक्षर्षिअलंनामिनामनक्षर्षिसनिचेतानामनक्षर्षिवृक्षनामनक्षर्षिजामुसिनामनक्षर्षि
गमक्षसानामनक्षर्षिव्रकवृक्षनामनक्षर्षिसविसृक्षनामनक्षर्षिगमनानामनक्षर्षिकाक्षीवतानामनक्षर्षी
कक्षायतानामनक्षर्षिकाक्षुयनानामनक्षर्षिहिरण्यानामनक्षर्षिहिरण्यनाकृतनामनक्षर्षिकपिलानामनक्षर्षि
रेभसेनानामनक्षर्षिमादृतनामनक्षर्षिसादिगास्यानामनक्षर्षिसुनगानामनक्षर्षिसुसेमिनामनक्षर्षिा
अत्रिनानामनक्षर्षिवाश्विश्रियानामनक्षर्षिनारदानामनक्षर्षिपर्वतानामनक्षर्षिकक्षिसानामनक्षर्षिकक्ष
यणात्रानदीसानीमनक्षर्षयावदानीकर्मसामग्रात्पर्वयिनासाप्तापानींदानाकृतावनामनक्षानंजसाहिकु
क्षिद्वयसाकनाकेपवनयानक्षानायूर्यविद्यासाक्षात्वनक्षिप्तासक्षांकुर्वतुजिवेद्वुवर्षसहंयन्भुक्तदासनेन

मघ॒क्षा॥ हि॒सि॒र॒वि॒सि॒नि॒सि॒मू॒सि॒हि॒सि॒मि॒सि॒ꣳ॒ हू॒त॒त॒ हू॒मा॒स॒नि॒द॒द॒नि॒य॒व॒नि॒या॒व॒नि॒॥ न॒य॒नि॒ना॒य॒नि॒॥
द॒न॒सि॒द॒स॒द॒दा॒स॒नि॒पा॒त॒नि॒मा॒द॒नि॒ज॒स्क॒नि॒स्व॒य॒ꣳ॒ वे॒स्वा॒हा॥ ॐ॒ ऋ॒ꣳ॒ क्ष॒ मा॒न॒द॒म॒हा॒प॒जा॒प॒ति॒नामा॥
नि॒य॒द॒वा॒नाग॒म॒य॒क्ष॒म॒सू॒दा॒सू॒ग॒सू॒त॒किं॒न॒स॒न॒ का॒स॒म॒गा॒प॒क्षा॒ता॒क्षा॒स॒न॒नू॒ष्या॒म॒नू॒ष्य॒ नि॒र्य॒ꣳ॒ स्व॒ नि॒स्व॒ज॒न॒
ल॒क॒म॒नु॒स॒स॒प॒रि॒ल्यि॒सं॒ख॒यैः॒स्व॒स्ति॒ वि॒म॒ष॒ ले॒सा॒के॒य॒व॒स्थि॒ना॥ न॒य॒था॒व॒का॒प॒जा॒प॒ति॒.ह॒गु॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ १२१
प॒जा॒प॒ति॒.ह॒गु॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ प॒ल॒स्क॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ पू॒ल॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ म॒नू॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ श्व॒सि॒ष्क॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ स्व॒न॒नू॒प॒जा॒प॒ति॒
स्व॒नं॒द॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ द॒क्ष॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ स॒न॒कू॒मा॒स॒प॒जा॒प॒ति॒भ्या॒ꣳ॒ हू॒स्व॒ हू॒स्वा॒नं॒द॒म॒हा॒मा॒न॒.प॒जा॒प॒त॒या॒ स्व॒ व॒स॒ज॒मा॒न॒स्य॒
हू॒ता॒गा॒म॒ स्व॒स॒क्षा॒र्थ॒ य॒व॒स्थि॒ना॥ न॒य॒न॒या॒म॒हा॒मा॒यू॒र्यो॒वि॒द्या॒सा॒ हू॒स्वा॒ग॒ह॒क्षाः॒स॒क्षी॒कू॒वि॒ऊ॒ह॒ि॒वं॒ऊ॒र्व॒

स॒न॒म्यु॒क्त॒स॒दा॒स॒तां॒ऊ॒ मे॒ग्ध॒म॒त॒प॒दे॒स॒प॒रि॒द॒दे॒ल॒क्षां॒कू॒वि॒ऊ॒स्वा॒ग॒ह॒क्षा॥ न॒य॒था॒ हि॒सि॒र॒वि॒सि॒सि॒
सि॒र॒सि॒सि॒ल्क॒र॒सि॒सि॒र॒हि॒सि॒र॒मि॒सि॒र॒मि॒सि॒र॒सि॒सि॒स्त॒ हू॒त॒त॒ हू॒मा॒स॒नि॒म॒थ॒नि॒द॒द॒नि॒या॒त॒नि॒य॒व॒नि॒या॒व॒नि॒
द॒हू॒द॒द॒दा॒स॒नि॒पा॒त॒नि॒मा॒द॒नि॒ज॒स्क॒नि॒स्व॒स्क॒नि॒य॒स्वा॒हा॥ ॐ॒ ऋ॒ꣳ॒ क्ष॒ मा॒द॒न॒म॒हा॒वि॒द्या॒प॒मा॒नि॒॥ न॒य॒था॒ꣳ॒ स्व॒
ल॒मु॒लो॒प॒मु॒लो॒क॒ल॒दा॒क॒यू॒लो॒हू॒न॒म॒हू॒त॒प॒नि॒वि॒द॒य॒नि॒सि॒सि॒प॒नि॒॥ प॒जा॒प॒ति॒ नृ॒जा॒ग॒प॒नि॒या॒ष॒भा॒य॒नि॒ꣳ॒ र॒
ता॒त॒स॒ता॒द॒ना॒म॒हा॒का॒हा॒ज॒ल॒ना॒म॒ त्रा॒द॒ल॒ा॒ग॒मु॒हा॒वृ॒ वि॒सा॒द॒नु॒ला॒ꣳ॒ हू॒सि॒वि॒कि॒वि॒का॒ क॒म्वा॒स॒ते॒नु॒ला॒॥ वि॒प॒
सि॒र्वि॒ति॒स॒ग॒ा॒सि॒ꣳ॒ हू॒ऽरा॒म॒म॒नि॒ज॒म्बू॒म॒नि॒म॒धू॒म॒नि॒क॒म॒स॒वि॒म॒सा॒ऽरु॒द्धि॒तु॒हि॒दू॒हि॒वा॒ क्ष॒व॒ क्ष॒दे॒॥ व॒
स॒म॒ना॒ रु॒म॒क्ष॒ान॒ग॒लो॒ऽत॒व॒द॒द॒स॒ल॒ं॒व॒स्वा॒हा॥ ॐ॒ ऋ॒ꣳ॒ क्ष॒ म॒हा॒वि॒द्या॒ ऋ॒प॒न॒या॒म॒हा॒मा॒यू॒र्यो॒वि॒द्या॒सा॒

हारिद्रकरिञ्जालक्षांकूर्वंतुरिवतुवर्षसतपूरन्धनुसदासतं॥ऽगस्त्यमानदमहादक्षानामानि॥तथाकौंचनीनामहावी
क्षा॥विष्यलानामहादक्षाऽरम्बस्थनामनमहादक्ष॥कपित्थनामनदक्ष॥ऽदुम्बनानामनमहादक्षा॥कपितनाना
मनमहाविक्ष॥क्षासानमनमहादक्ष॥कर्नीकासानामनमहादक्षा॥निम्बनामनमहाविक्षा॥विसानामनमहादक्षा॥
चूतानामनमहाविक्षा॥सिचूतानामनमहाविक्षा॥ऽऽम्रजंबानन्यवानमहादक्षा॥कथ्यपिवयादवता॥पनिवनि॥ १२२
कथ्यनयामहातायूर्यांविधासाक्षासवाकरिक्ष॥सक्षांकूर्वंतुरिवतुवर्षसतपूरन्धनुसदासतं॥ऽऽर्यंचानदमा
क्षामयूर्यांविधासाक्षासकरिक्षःसंभ्यक्कींवूर्ंडुरोधिनावाह्यनूमादिनाव॥तथाअविषस्थिनामसंभ्यक्कींवूर्ये
क्षारिवनाह्यनूमादिनाव॥सिरिवनासंभ्यक्कींवूर्ंडुरोधिनावाह्यनूमादिनाव॥विष्यक्सेनवासंभ्यक्कींवूर्ंडुनक्षारिवना

वाह्यनूमादिनाव॥कक्कटकदनसंभ्यक्कींवूर्ंडुनक्षारिवनाह्यनूमादिनाव॥सिरिवकनकमूलिनासंभ्यक्कींवूर्ंडुरोधा
नावाह्यनूमादिनाव॥काश्मर्यनसंभ्यक्कींवूर्ंडुरोधिनावाह्यनूमादिनाव॥मयाबेलदिमधुकमूलिनासंभ्यक्कींवूर्ंड
नक्षारिवनाव॥ऽऽर्यंचानदमहासायूर्यांविधासाक्षासमेनयनवाविसत्वनमहासत्वनक्षारिवनाह्यनूमादिनाव
वक्कनासक्षाविषनिनाक्षाधिनावाह्यनूमादिनाव॥कसनदवानामिदनक्षारिवनावाह्यनूमादिनाव॥वकुली
स्वमहासाजेक्षाधिनावानूमादिनाव॥धवेलाक्षूनागधवमहासाजेनक्षाधिनावाह्यनूमादिनाव॥विसूधकेन
कुम्हाकुमहासाजेनक्षारिवनावाह्यनूमादिनाव॥विसूपाक्षनेनासाजेनक्षारिवनावाह्यनूमादिनाव॥वेसव
लनयक्षमहासाजेक्षारिवनावाह्यनूमादिनाव॥ऽऽक्षाविसनिरिक्षगधवंसनात्रिरि॥ऽऽक्षाविसनिकुम्हा

ब्रुसनापतिहि॥अरक्षाविंसतिस्विश्वनागसनापतिहि॥अरक्षाविंसतिस्विश्वयक्षसनापतिहि॥पांसिकनव
यक्षसनापतिनी॥स्विश्वहस्तिस्यावपंवसतपूघसिवासखिनावानूमादिनवा॥कूर्यंवानसमहामायूसिवि
घासाक्षअनंतिकमनियाय॥धवग्रहनानागग्रहा॥अस्वग्रहनामसूनग्रहानागधवग्रहनाकिनसग्रहा
मानहासग्रहनायक्षग्रहनासाक्षसग्रहनापतग्रहनाखिसावग्रहनाहनग्रहनाकूष्मानूग्रहनाकनप
हनाकनुग्रहनाऽमानूग्रहनाकूयाग्रहनाअपसमासग्रहनाऽऽक्षासकग्रहनाअनंतिकमनियास
वग्रहनाअनंतिकमनियासवीजाहासिस्विश्॥गहासिश्भा॥सूखिसाहासिस्भावसाहासिस्भाःमासाहासि
मदाहासिस्भाःमजाहासिस्भाःशोहासिस्भाःजिवाहासिस्भाःवस्याहासिस्भाःमास्याहासिस्भाःघ्रमहासिस्भ

वृषाहासिश्भाःपूष्माहासिश्भाःकसाहासिश्भाःसस्याहासिस्भाःअक्रूयाहासिस्भाःविष्ठाहासिमश्भाःमूताहा
सिस्भाःखेटाहासिश्भाःस्वेमाहासिश्भाःसिंहानकाहासिश्भाःऽर्कऽकाहासिस्भाःवाताहाश्भाःअस्थाहा
सिश्भाःस्वदनिकाहासिश्भाःअनंतिकमनाकास्वदकिसनवनातविवषकदूऽकदूकसायादूषक्षि
दनदूसिखिनदूसंधिनावधूनी॥अनंतिकमनिसजासहात्रकादिकनछेदियकनवाचुर्थकनसफाडिकन
अवमासिकनमासिकनदेवसिकनामूहुर्तिकननिखहसनाविषमहसनहूतहसेनपतहसहामानूष
हसेनावाहिकनपेनिकनस्वविषमकसंनियादिकनअनंत्रिकनियासवहसनाअनंतिकमंतिसिसावंति
अस्थाऽवकनासावकनाक्षिरागसमूखरागकथरागनहृदयरागनगरागनकनमूसनहृदयनुसनप

र्वभूसनपदभूसडदसभूसनगभुनसेनविरिष्ठभूसनयानिभूसनपजनभूस डस्भूसेनजंघासभूसनहस्त
भूसनबादभूसडाश्रंगपर्यंगभूसडाश्रनंतिकमनियादद्रकनुकिंतिमकूष्कादसगहुपिनकपामाश्रेम
पसाहलिंगाश्रनंतिकमनियासवद्यामिहिंसवदूषेसर्वविर्धसकृयेसवनिहिंसवकासिकसहायदवाय
सहमेपायासे यस्यमीश्रानदमहामायूसिविद्यासाहश्रनंतिकमनत्यवजपाभिसफवासहकामूखमग १२८
कस्यवमजसिस्कृतयीत्यंतिासर्वविूहशमिसत्वपत्यकवूद्ध्रश्रवकानांगजसाहष्टसाकानष्टवेनस्य
यपिभ्रसाहनविसंवदिवारुक्यावद्यासामहासाजानश्चनश्रीपयसासफेमहातंव्यंनमापादय
यूणाकक्ष्यास्यदवानामिदक्षिदसगहायसिदहावजनमद्धानमहिहियातावक्रनंगसावाद्यविरु

निरुसमसागमश्कनश्रनयावानदमहामायूसिविद्यासाहश्रायस्यसहंकिपत्रसूनंपसिवावद्यकासर्वभा
र्हिश्चानदद्रकुनमाक्षनादद्रकुपकासेहायहसहंसाकाश्रानश्रोकासहंपसिकाश्रनयायसिवहमहं
सामहषसिहासामहषनाद्रवंमवमाक्षनानवासेसाक्ष्यंहविद्यंतिनाश्रंसेसक्ष्यंहविद्यंतिनाभिक्ष्यं
हविद्यानादकासनकसिद्धंतिनस्सहकसिमिद्धंतिनवासवकार्यंविषंकमिद्धंतिसर्वंवसपत्यंति
सहवचयंतिवूद्ध्यकाश्चहनिसूपदवानिसूत्रासानिरुपहथिकानिरुनयकमिकानिसूपकृतासवल्पवि
निमूलासहंविसर्जिविद्यंतिस्कूपसिस्नान्दयेसानीकमविपाकंहूयंवानदमहामायूसिविद्यासहं
श्रंतिविक्षावपथिनद्यातनस्वनागमोसक्कमापस्यकाश्रंतिदृष्टिंनिगृह्कनिश्रनाविहिंधारं

पातं कृसिर्व्वंतिर्यावत्तस्यकूलखूनस्यवाकूनदूरिनुवाऽरविषायारुविर्व्वंति॥ऽस्यक्षनंदमाक्षामायू
विद्यासाहूस्मलनादवसवरुयरुसवेसानिषसनिरुविर्व्वंति॥कीपूसिमाकसस्मींकामषभ्रुयाभयस्य
स्रुयनंवाकूर्यनि॥ऽमृक्षत्वमानदङ्गंमक्षामायूसिविद्यासाहूषर्यवापूहिभासयवावयमाक्षामायूसिवी०२५
द्यासाहीसर्व वेसयशमनिवनस्तरभंषर्वदीसक्षावसनंगुफयाहिङ्किनाक्षिक्षिनीनीऽपासकानांमूयासिक
नावाणपथा॥वयानिक्षवनिकूसऽलूसल्याक्षा॥साम्रुषमाहनवयरुसाकेनयाविषा॥विषारुगवावृज
स्यरुनंविर्षासागरुषऽमाहृत्रुनेसाकेनयाविषा॥निविषारुगवाषमसत्यरुनविर्षा॥साम्रुषरुषमा

ब्रुनराकृनयाविषा॥निर्विषारुगवासत्यरुनायरुसंसवबृहनीरहनांवेवयषा॥नथागनस्यनजेनकृनं
स्वस्त्यनंमयाक्षानेहिक्षासवस्वानीवहनविषमाक्षामायूविद्यासाहूस्वस्त्यनदस्वानेहिक्षारुगवनसावृरुगवा
निस्त्रायूष्मानोम्नदारुगवनऽक्वनंपक्रिरुगवनयादीसिलसाहिवदिस्त्रारुगवनपदशिनिकूस्त्रयनस्वा
निहिङ्कृनापसंकातऽपसंकम्यस्वानक्षिक्षीसनयामहामायूर्यीविद्यासाहीसाक्षामकाषीगुफीपसिगहीं
पसिगह्यपसियासनंक्षानिचस्त्रायनंदहुयसिहासनंमरूपसिहासंविषदूखनंक्षेनासनंसिमावष ऽमकाषि
नावूहिन ऽयूष्मास्वानिहिक्षूरुतमादावंऽयूष्मानाऽज्ञानदनक्षास्वास्त्रयनेदूनपऽरथायूष्मीरुस्वानी
स्थिरुयनरुगवीरुनापसंकाऽऽऽपसंकम्यरुगवनमादासिस्तारुविवंरुगवंनसवयथाविषाबृलानंविवक्षात्री

निषनाथ रुगवानायूष्मन आनन्दमूवाच। इहखलु मद्दामायूर्विद्यासाहस्यकाथनिः। तथाद्यादिनैरुगतमानन्दपदात्मावा
वाद्यिमिर्दंरुगवनविदिनैरुविद्यनिः। रुगवदूनसूवाच। अथखवानन्दवक्त्वासामद्दासनमुद्दा। अभयमागच्छपूर्वाधिविद्याश्रा
कासमूर्यघनाचदादिखोवाधर्थिखीनिषनानयावाधकिलमागच्छपुनर्वनथागतवचनन्वथारुवादिखी
अथरुवानायूष्मीनमानन्दमामनयनेत्स्यामितमालक्रिचमानन्दञ्ज्ञमीनाद्दामायूसिविद्यासाहीवनशुभप १२८
सिषमादासोक्षिक्षनीक्षिक्षनिनीमूपासकामूपासिकानाचनिः। सावरुगवानक्षिखायूष्मामानन्दारुगवनः
क्वनंपक्षिक्रयञ्ज्ञमीमद्दामायूसिविद्यासाहीवनस्यमीपसिषदामासावयनिः। क्षिक्षनीक्षिक्षनिनामूपास
कामूपासिनाचे॥ ॥ॐदंनयोचरुगवानायूष्मनानन्दमायूष्मा ॐस्वाक्षिक्षर्यवनस्यीपसिषदिमंनि



नानिस्तनिषनादवानायूष्मन्तरुगासूतकिनसगधवनरुगयक्षराक्षसमनूष्यामनूष्याश्चवरुगवनोरुगखि
नामस्वनदनिनिः॥ ॥आर्यमद्दामायूर्विद्यासाहस्यअविनक्षयक्षमूसुनिसञ्ज्ञातमाश्च॥ ॥
ॐनमारुगवन्तेआर्यमद्दामानवस्यैप्रज्ञापारमितायैनमः। कविमहासमयरुगवानराजायरुविहरतिस्मा॥तीव
वनेमद्दाशालमानेञ्ज्ञरिकायतनपस्यूरुता॥तेनायूष्मासारिपुत्रानिवविधुभगादवृगरुनागरुयक्षग
रुगासुरुगरुगमनूरुगरुगरुडरुगरुकिनरुगरुगरुडरुगरुगधवगरुमहारुगरुमनूष्यगरुसमः
नूष्यगरुपनगरुविद्यावगरुकक्ष्यानुरुछायीरिकाकोटीः॥सरिरपेस्यथमनूष्यामनूष्यः
सत्त्वश्चायूष्मानसारिपुत्रायनरुगवांश्चनायस्कानःउपस्कन्धरुगवनःयाधाकिलसावदिरुगग

वैद्यनिघण्टौ कृष्णगवादिपूतनादिसूदनश्च निघण्टयमित्तम्॥ अथ कृष्णवाजाननवराहसमानतया तत्र॥ किञ्चि
राहसमानपूतनाश्चित्वाऽश्वश्च निघण्टयमि॥ ब्रवंमूकश्वापुषमान्नाहसाकृष्णवर्णमतदवाचक॥ कृष्णांकृष्णवा
राजगट्टकृष्णविद्रलामि॥ सिनवनैमत्तकाश्वघाने कृष्णिकायतनपत्रनपत्रकृष्णाअंकृष्णवंकलम्बिकृष्ण॥ देवगदना
गदेयक्षगदेराक्षसगदेमनुष्यगदेमनुष्यगदेकिन्नरगदेमनुष्यगदेगंधर्वगदेमनुष्यगदेमनुष्य
ग्रहेपक्षिग्रहेरक्षोग्रहेपिशाचग्रहेकूष्माण्डग्रह॥ हिंपिहिंकाकेसूकरकीडेसिंहेपेत्स्येचमनुष्यानमनुष्यो
सर्व॥ अथवराहकृष्णवानायूषमर्तसाहसमानंतयातत्र॥ उक्तंचराहसमौ हनीमतासिनीमतानीविद्यावतस्तत्प्रय
षमदासक्षावतनगुफया॥ रिक्षूनारिक्षूनीनामुपासकानामुपासिकानांच॥ सवसच्चानीचादियतातमथायहि

गायत्रकायकायगक्षमायकविद्यानिगदयथाऽरंगमवंगमकसिंगमवतंगमसंसातनसंगमसातदंगमहृगा॥ अस्तसावक
तलंगमऽस्तसविसागतसविसागतसतसविसागकसविसागकसकलविसाऽन्दाऽन्दकिसलाहंसादंसकिसलापी
यिमसामहाकिंवाविहठिकाकाकसूचिकाऽरसदलाजयासिकावैसायसाविसासिचिसिचिसिहिर
सिहिसिमुमतिवसमतिचूसनहूचूसचूसनहाचूसचूसचूसनहाचूसनादिकूनादिहासीटकिहासि
हूकिहासिटकिकासिटकीहकसिटकिकसिटकिहागमेसिगमासिवसुसिवकासिमागमीवचसिवसनिवा
सनीतलमितासनिऽसूमासिकोकवकाविकंकवकाविवाचलनासिकाकासिकासलमतिसक्षमतिकवता
तकसेमऽयसऽयसेकसविसेकलकसविसेतसविसेतसतसविसकूसविसेकूसकूसविसेचूसविसेचव

गछेवामूदाक्षि वानेवमनूक्षावाःश्रमनूक्षावाःश्रक्षिरु विक्षतिःानविषंनअस्कनसागमनहसानविधामशनवेषाउ॥
नव्याश्चिर्नानाग्निनानविषादकनकालकस्यिनाःविधामतपजागमनांवसवेषौसाधूपयूक्तानांवासिद्धानां
सिद्धकस्यिसिद्धाना रुसंक्षारुनिपस्तपयूक्तानांववंधनोपस्वंधनानांवपभाचनोस्तर्वसागरुभकविघ्नवि
नायनीकविसनकस्यिकस्यिकस्यरुकस्तूषपसमनकस्योस्तवगदरुविभावाकनस्यिजागरुक्षानमूर्खनास्यफ्ध
स्यस्यरुगमूदाश्रजकस्यवमरुस्यिवजयाःस्यिअस्यमहायरुसनापतिर्वजदभादिफनहस्यिनेनत्रकहास्यिः
हस्तनाभावरुक्षायपाचमूधानीस्तदयनावचास्यमहाराजानोश्रयामयनवरुक्षासमूदानीस्तदयय्यूभूस्थ
सापहासेहस्तवविघ्नभययूःनसमावयरुसाकाश्चयवनरुवयूःश्रउवस्यसाजश्चन्यानसरुनेवात्मानश्रस्याखस्पू

साधुसमहास्तिनवनिविधायाधाःस्तस्यस्यिवस्यिनायीःसाहसेसादकाग्निविषस्फादविकानासदूरमिश्चगतास
वरुपस्यपस्यिमश्चनाःऽूर्यंखस्तूपूनामहागीनवनिविधात्रकनवस्यीगंगमनदिवासिकासमवृद्धेरुगवकि
लाषिताकाषिश्चरुवनिज्ञापसमस्तिधास्तिपस्तामंकास्तवदेवनागयक्षगधवास्तूतगतकिनसरुक्षासमाद्रि
रिवंदितास्तवजिनगणपसिद्धास्तवरुयापडरुक्षूवनमंसर्वसत्वानाकसरुक्षीकूस्तूस्तिवमासाःस्तमरुयरुक्स
र्वकासवयासवनासवाःवस्तस्तवऽ॥ऽूंदंनमोवरुगवानामरुनाश्रायूवमासाधारुसा॥सावस्तवविविधर्षस
रुवामानूषास्तसमस्तूगंधर्वसराकारुगवनरुक्षाषितमश्चनदनिनि॥ ॥श्रार्यमहागीनवनिना
नमस्कृत्याविद्यासाधनीसमाकल्पं॥ ॥ऊँनमोरुगवश्रेश्रार्यमहासत्रानूसारिणीं॥नमोविद्यारुाजायन

सूसूसूसूसूसूसूसूसूसूसूसू॥ ४ ॥सूसूसूसूसूसूसूसू॥ ४ ॥पूपूपूपूपूपूपू॥ ४ ॥मूमूमू॥ ४ ॥
पविनाशितसूसू॥मूसूसूसूसूसूसूसूसूसूसू॥ ८ ॥मिसिमिसिमिसिमिसिमिसिमिसिमिसि॥
८ ॥मूसूमिसिमूसूमिसिमूसूमिसिमूसूमिसिमूसूमिसिमूसूमिसिमूसूमिसिमूसूमिसिमूसू
मिसिमूसूमिसिमूसूमिसिमूसूमिसि॥ १२ ॥मूसूसिमीमूसूसिमिमूसूसिमिमूसूसिमि
मूसूसिमि॥ ६ ॥सिसिसिसिसिसि॥ ७ ॥सीसीसीसीसीसी॥ ७ ॥मिसिमिसिमिसिमिसिमीमी
मिसि॥ ७ ॥मिसिमिहसिमिसिमिमिसिसीमिमि॥कढाकसंकढाकङ्कसाकङ्कसाकङ्कसाकङ्कसाकङ्क
साकङ्कसाकङ्कसाकङ्कसाक॥ ८ ॥कङ्कसाकङ्कसीनिकूसिषकङ्कसीकङ्कसीकसि॥सिसिसिसिसि

सिसि ॥सूकूसासि॥कूसिकूसिकूसिकूसिकूसिकूसिकूसिकूसि॥ ८ ॥कूसाश्रनाथसिसिधिकूसिसूसि
पक्कसिश्रनाथनाथनिर्गकूनसिपूंनिर्गकूनापसायनसिपूंपसायनायदियूपंदृष्ट्विनानयसायनः
सयनावृज्ञासाकानूकंपकन्नवंमास्कापयतिप्रविसतिसवीसत्वहितायाभयामेतिविकासिकासूसि
कामूदितविकासिसिन्नमनपदासिअसिद्धगाथाजिनादिनासर्वेषांदेवतानांहितकाकहिंसृषि
र्नासंस्कानानाथस्कूसनाघतधर्मनयाविवाजगतामियतसर्वासाम्यत्वासाम्यमस्तुवाविश्वकिकाय
दृष्ट्वाविश्वस्तावितसीकृतासानविनाकृनायासर्वास्त्रिकसिद्धयतिसायाजगत्साक्षुमाशेसिमन्नि
वसतिनायकोदेशकस्तवधर्मीभूसर्वास्त्रिकसिद्धयतिसतिर्यागजतोभस्काकृतेयनसर्वंवहु॥

ॐ नमो विस्तृतविस्तृतविस्तृतविस्तृतविस्तृता जातिवृक्षाकानूकंपकदंबनमो नमो नमो नमो नमो नमो
वृक्षानूकंपकानूकंपकवृक्षानूकंपकानूकंपकानूकंपकवृक्षानूकंपकानूकंपकानूकंपकवृक्षानूकंपक

धर्मरत्न वज्राचार्य सुरत श्री महाविहार

II-111